ततो व्योमसमाकारा शिवस्यैवाकृतिं ततः ।

सा प्रविष्टा परिच्छन्नान्तसंरम्भेव महार्णवम् ।। VI (ii) 85. ||

पूणार्ण्वारं पतल्लोकलोकसप्तकमन्दिरैः ।
चक्रावृत्या प्रपद्रूपैरमरैः सागरैरिव ।। VI (ii) 77. २९.

क्रीडीकृतमनो बुद्धिमयजो वाप्यहंकृतिः ।

अन्तः स्फुरच्चमत्कारा रूपश्चैव नागरी ॥ Vi(i) P2. 8.

स्फुरन्त्यसुरवीराणां गृहेष्वविरतानिशैः ।
धूसरा पक्ष्मनोहारा धूपधूमभरा इव ।। V. 31.9.

यथा घूमस्य नपसि यथाम्भोवी महाम्भसः ।
आवर्तवृत्यश्चित्रास्तथा विद्योऽम्भि संसृतेः ।। Vi (ii) 100.42.

अथि, परीनाथ:

अहमर्थीहिमं त्वन्तरनहंता विदर्विषा ।

उद्दोयेन विनोनं सन्न जाने क्वाशु गच्छति ॥ V:(ii) 17.6.

विदूरव्याट्टहासात
अजस्रमभिनिर्ययुः ।
अम्भोधेरिव पयःपूराः सूर्यादिव
मरीचयः ॥

III . 48 8.

सर्वेषामुत्तमस्थानां सर्वासां चिरसंपदाम् ।

स्वपतो निग्रहो भूमिर्भूमिपः सस्यश्रियामिव ॥ V. 43. 35.

न हिमाद्रेर्न मुक्ताभ्यो न रम्भाभ्यो न चन्दनात् ।
न च चन्द्रमसः शैत्यं नैराश्यादवाप्यते ॥ V. 74. 43.

न हिमाद्रेर्न मुक्ताभ्यो न रम्भाभ्यो न चन्दनात् ।
न च चन्द्रमसः शैत्यं नैराश्याद्यदवाप्यते ॥ V. 74. 43.


~~[illegible]~~

नायर, दिनश्री:


अहपर्णः प्रविसृतः प्रकटीकुरुते जगत् ।
सद्रूपालोकमननं प्रवृत इव वासरः ।। V.(ii) 4.41.

न प्रसन्ना न विपन्ना बभूवाकुलतां गता ।

दिनश्रीरिव नीहारधूसरा सा व्यतिष्ठत ।। Vikr 85. 5.



हन्दुमण्डलमायान्तु रसनारसशकय: ।
निमैन्दर इवाम्भोधिर्गतार्क इव वासर: ।। V.86.5P.



कुमुदनी.

कैरव

कुरउं

कहलन.

विवेकिनो जगत्पूज्याः सेव्या मन्ये भवादृशाः
सत्सङ्गात्सविकासास्मि चन्द्रेणेव कुमुद्वती ॥

III 8 2. 6.

Sama IV-24.   a yea
Sari II-40.   a wat

Sala II-13, 37; III-51.

Sik III.4(fem)   garme

Sitya III-28   Corn
lexic

Stricell II.24   A vic
woman

~~Sumana (m) II-28.~~
Sumana (mas) II-28.whe

lexic

इन्दे ऽ यायाते सा
यावनानूनास्या विराजो
मुरकं सूर्गि चलेश्वर
पुरुडेरवि न दैरनमु।
III. 89.23.

जहर्ष जनितानन्दा वैष्णवी गतसंभ्रमा ।
जनता जलदध्वानफुल्लेव कुटजावली ॥ V. 39.10.

बभूव संप्रबुद्धात्मा दानवेशः शनैः शनैः ।
मेघावसर उत्फुल्लकदम्ब इव कानने ।। V. 39.11.

कदम्बगोलकस्तुल्यं ब्रह्माण्डं स्फारचेतसः ।

किं प्रयच्छति किं भुङ्क्ते प्राप्ते ह्यस्मिन्नकलेऽपि सः ॥ IV. 57. 38

जातो सौ वृद्धिमभ्येति पार्वणश्चन्द्रमा इव ।
कुटजं प्रावृषीवेनं सौभाग्यमनुगच्छति ।।

V. 6.7.

आवर्त [illegible] उपस्थान.

मूर्ति.

जीवस्य तरल: काय आवर्त: पयसो यथा ।
यथा बीजेऽङ्कुर: स्फार: पल्लव: स्वाङ्कुरे यथा ।। IV.44.7.

भू ।नि ते ।नामदानवानि

[illegible] पांडवाः स[illegible]म् ।


पर मा। [illegible]

[illegible] त्रितम् ।

Vi ।cl। 18.6

ततो मुहूर्तमात्रेण लघुः सो प्रभिवाभवत् ।
ततो पवर्धिष्टसमन्ततः प्रादेशमात्रकः ।। VI (ii) 86.6.

आवर्तः सलिलस्येव यः स्पन्दस्त्वयमात्मनः ।
प्रोक्तः प्रकृतिशब्देन तेनैवेह स एव हि ॥ VI (i) 49.30



सौदामिनी, विद्युत



वायुर्वायुविघट्टिताभ्रपटलीलम्बाम्बुवद्भङ्गुरं
भोगा मेघवितानमध्यविलसत्सौदामनीचंचला: ।। V:(i) 136.33

हृयज्जचक्रकोशो ध्वैं प्रस्फुरत्यानल: कणा: ।
हैमपद्मरवत्सांध्यविद्युल्लव इवाम्बुदे ।। V: (i) 82.2.



निरोध

सुशीतलोदकनदीं विदित्वाथ विगाह्य ताम ।
बहिर्भ्रान्तिनिदाघास्ते नियान्तु कलितासुखम् ।। V.(i) 127.21

शरत्

तपतीदं जग ह्य शरत्काल इवामलम् ।
स्फुरतीदं जगद्ह्य सौम्यः सोम इव द्रुतः ॥ VI (i) 47.19

वृद्धायां प्रावृषि भीमा शरत्मान इवागलः ।
विचारी भोगगर्हांतो विचाराद्भोगगर्हणाम् ।। V.24.62.

अशेषसंशयाम्भोदशरत्समय किंत्वहम ।
तृप्तिमेषां न गच्छामि वचसां वदतस्तव ॥ V. 22. 5.




ज्योत्स्ना.



ज्योत्स्ना.

स्वयमेकानयाद्गो तेन तामरसेक्षण ।
उत्पादिताऽस्मि नाथेन ज्योत्स्नेव शशिनाऽमला ॥ VI (ii) 64.47.


स्वयमेकानवद्याङ्गी तेन तामरसेक्षणा ।
उत्पादितास्मि नाथेन ज्योत्स्नेव शशिनाऽमला ।। VI (ii) 64.47.



ओम शि:

संसर्गेणान्तरस्थेन दह्यते प्रकृतिः स्वयम् ।
स्वकर्मोत्थैर्नरकाद्दग्धो पावकेन यथौषधिः ॥ V. 68. 57.

भगवन्सर्वीवर्यश्च शुद्धैस्त्वद्वनांशुभिः ।
निर्वृताः स्म शशाङ्कस्य करैरौषधयो यथा ॥ V. 43. 8:



যোগি নীলিমেব. স্ফুরতি.

सर्व स इत्यनामुके गीता
चाआगि निमले।
स्फुरन्ति विलते [illegible]
गीति के काराय हुए हैं॥
११.९५.

To

The Vice-Ch
Kuruksetra
Kuruksetra.

Sir,

For some ti

प्राणरूप दमैवे दें
(चि महेश हूं दरखते।
जागनूतामागतं सोमिके
मीतालता देवदी दूशाम॥
V. ९१. 17.

means a collection,
is outside. So that
be the land which i
village. 'Sumudaya
the community, i.e.

SAṂDHIVIGRAHIKA -- Lit. 'An
title. Other syno
(IA, VII, 70, 1.17
175, 1.18), and S

न कुन्तकाङ्क्षेञ्जलधिनं रज्जोऽप्यनं पर्यस्तलम् ।
न प्लायन्ति निर्जलौकव्यवहारैरिहात्मवान् ॥ V. 72 . 26.

कुन्तकाङ्क्षे, रज > लोकव्यवहार जलधि नमस्तल > आत्मवान्

प्रसत्यैव जगज्जीवो वासनावल्लिश्चिरम् ।
ऊर्ध्वाधोगमनैरब्धौ काष्ठं वीचिहृतं यथा ॥ VI (1) 50. 22.

[illegible]

[illegible]

काष्ठ

लोष्ठ

आत्मन्येवैष मूकात्मा ध्यानवानवतिष्ठते । Vi. 13.20

संचात्यते परेणैव तरङ्गेणेव काष्ठकम् ।।

संरुद्धे पर्यन्ते हि प्राणे ॥
शान्तिमुपागते देहः पतत्युर्व्या-
मडियं काष्ठलोष्टसमः क्षितौ ॥
6.(i) 32.36.

The answer of the Vaiśeṣika to this
e of time as the cause of an indirect
and an individual substance is proved
of the other possible causes. The
produce the relation in question is

गते श्रावणपक्षस्य राज्येऽग्र [illegible]पमागते
दिक्षु संक्रान्तरूपासु काष्ठमास्थितास्विव ॥

~~६. २९.~~

६. २९. ९२

are two different actions, one
f the mind. The action of the senses is
ontact. The action of the mind is

2.49.

यथा काष्ठानि नयति प्राचोदेशं सरिद्रय: ।

तथान्नानि नयत्यन्त: प्राणवात: स्वमाश्रयम् ।। V.ii, 81.36.

दूरस्थिता दृशि सिताभ्रपटा वदन्ति
संशुष्कपर्णनिवहानि घनोष्टलोलाम् ॥

Vi (ii) 115 · 2

कृप

अन्धकूपे इवापत्रः शिलान्तरिव योजितः।
स्वयं जडीभवद्वर्णो विनिकृत्त इवाशये ॥

III. 54. 44.

Varavarnini. IV.41. Lac.

Valaja. III-40. The

Kosas

Vasa. II-40. Any

eleph

Vasati. IV-9. Nigh

Vana, II-38. Drie

मणि, स्फटिक, मुक्ता, रत्न
वज्र

उवाच वचनं घोरं कुमाराभिमतं वरम् ।
गृहाण स्थापितं साधो कोशाकाशान्मणिं यथा ॥ (V) 48.38

भाजनं त्वं विविक्तानां वचसां शुद्धिशालिनाम् । V. 4.23.
विविक्तहृदयः कण्ठे मुक्तानामिव राघव ॥

रथ्यं पुण्यं पवित्रं च रत्नवृन्दमिवान्वितम् ।
ददतो नमदो नात्मन्यसर्वंपन्तः कृतं मया ।। V. 4. 2 8.

यस्येदं जन्म पाश्चात्यं तमाश्वेव महामते ।
विशान्ति विद्या विमला मुक्ता वेणुमिवोत्तमम् ।। V. 6. P.

एतावन्तमियं कालं मनोमुक्ताफलं मम ।
अविद्धमासीदधुना विद्धं तु गुणमर्हति ।। IV ९. 61.

यथा मणिदर्दात्यात्मच्छायाः स्वयप्रकारणात् ।
तेजोमयोस्तथैवायमात्मा सृष्टेः प्रयच्छति ।। ६. ५. ३७.

मुख्यं कारणमात्मैव परमात्मावलोकने ।

अगाधे पतितं रत्नं रत्नेनैवावलोक्यते ।। V. 50. 27.

.. x . 3x. 66

हृतद्वारकपाटासु दैत्यान्तः पुरभित्तिषु।


प्रभा परकतस्यैव जाता नवयवाङ्कुराः ॥ V. 31. 10.

52.66

वासनैवेह भवतां हेतुरेकत्र बन्धने ।
रज्जुः शन्याशयप्रोता मुक्तानामातता यथा ॥ V. 52.66.

त्वयि सर्वमिदं प्रोतं जगत्स्थावरजंगमम् ।
बोधे नित्योदिते शुद्धे सूत्रे मणिगणा यथा ॥ V. 29.47.

V. 12.



यथाप्राप्तानुवृत्तिमान् ।

निर्वाणो एव शान्तात्मा

स्फटिकादिव निर्मितः ॥

सन्नेवासत्सम: सौम्य

V.(ii) 27.1.

V.12.

उड्डीयन्ते शिला: स्थूला: पदावन्तो यथाद्रय: ।
शिलान्त: प्राप्यते सर्वं ननु चिन्तामणीरिव ।। VI (i) 61. 23.

उड्डीयन्ते शिलाः स्थूलाः पक्षवन्तो यथाद्रयः ।
शिलान्तः प्राप्यते सर्वं ननु चिन्तामणीरिव ॥ VI (i) 61. 23.

यथा शिलान्तरणूनां स्पन्दास्पन्दभवाभवाः ।
विषयत्वं न गच्छन्ति कर्तारो जगतस्तथा ॥ VI. (i) 46.37.

चिन्तामणिरियं प्रज्ञा हृत्कोशस्था विवेकिनः ।
फलं कल्पलतेवैषा चिन्तितं संप्रयच्छति ।। V.12.34.

कैशेन्द्रनीलवलया भ्रूविलासतरङ्गिताः ।
नितम्बपुलिनस्फीताः कण्ठकम्बुविभूषिताः ॥ V. 76. 10.


तासामुत्तरदिग्भागौ पूर्वशृङ्गशिलोदरे ।

निवसाम्यहमद्यापि वज्रसारसमत्वचि ॥ VI (ii) 64.35.

मृदुशीतलसंस्पर्शो यः समाह्लादयन्मनः ।
सुज्ञानां द्रवति स्निग्धस्येन्दोरिन्दुमणिर्यथा ॥ Vi(i) 74.8.


इन्द्रनीलाद्रितुल्योच्चतोरणोच्चैः प्रभाभ्रे ।

विश्रान्तोक्षा क्षेशेना मभगभो षणवायसो ॥ VI (ii) 81. 27.



कोशाचा क्र

प्रद्युम्नशिखरं नाम तस्य मध्ये भविष्यति ।
श्रृंगं लघु सरोजस्य कोशवक्रमिवोदरे ।। (V. 32.12



सुरती

सदृशयोर्धुरवैर्धुभूम्योरिव कान्तयोः ।

नित्यमेव वियुक्तत्वात्प्रियत्वाच्चेष्टितस्य च ।। Vi(i) 77.43.


नैतयम्

~~Ocean~~

~~Ocean as an [illegible]~~

मांसं कुयन्त्रजठरे स्थितं श्लिष्टमुखं मिथः ।
ऊर्ध्वाधः संपिनत्स्थूलद्वयमश्मः स्थैरिव वैतसम् ॥ Vici I 81.63

प्राक्र्



नां स्य (आमिषस्य) तज्जात-
या बह्वन्प्राकस्मृतिवर्तमान-
यां । शरदेवोपगतया प्रावृड्-
जाड्यापवारिणी ।।
6.(i)33.47.

ऐसी ध्वनि को सुन
बरबस उपर खिंच ज
जाते हैं और गुरु
गुजरती हुई कामिनि
विलासिनीनां
दुनिरत्वं गु

गुणाः , तन्तवः etc..

[illegible]
[illegible] ।
[illegible]
[illegible] ॥
५-१२-२८

.46)

ld.(Nos. 16,18).

architects'. The meaning is not quite

may mean 'superintendent of the

men's apartments'.(Fleet : No.26).

ly title (No.72).

ritorial division near Sāñcī(No.5).

coin or weight of gold(No.[illegible]

वन राज्यजराजीर्णाः कन्दाकस्थल-
जन्तवः ।
अत्रुट-परमाकृष्टाः पेलवा इव
तन्तवः ॥

III. 37. 47.

ती कथा (उन्मदन्ती जातकम्)

स्वानन्दकान्तविमेवारु
दूरसते ना चिकारिणः ।
गाशां तनें महा-
हिर्नन्देन्द्रगुणातिदेव ॥
V.(i) 6.28



[illegible] . मृत

[illegible]

स्थापिता मलमादेत यथा गृह्वर्जिं तिना।
परापराचांतरहाद्याधिस्तस्याः प्रवर्तते ॥

3. 70. 80

है। कवि के आत्म

ऋग्वेद

रूप पर्याप्त की और

यदु वा

वस्तु व

देवी वाम्म

था भी मन्


दोनों


यद्वद्वयात्मापि तुर्यश्च या विद्या प्रकृतिश्च या । VI. (i) 49.28.

तदभिन्नसदैकात्म यथा कुम्भशतेषु मृत् ॥

डिण्डीर, मध्य प्रदेश

फेविल





प्रभ्रमत्पुण्यडिण्डीरी ज्वलन्नक्रवाडवः ।

तृष्णाविलोललहरीमीनो जलमतङ्गजः ॥ V. 76. 6.

[illegible]: 11

[illegible]: 1

त्रिलोकोविलिखल्लेखो विलोकालोकफेनिलः ।


ब्रह्माण्डबुद्बुदोद्भेदः कवाटापोढपोवरः ।। V. (ii) 15.7.

शान्ति:, सत्य

नाभापते मनुष्यस्त्वा कादृशातापि शठात्मना ।
पुत्र शान्तिरिवा व्युप्ता तस्मादेनां समाहर ॥ V. 24. 21.

सुखदुःखान्युपायान्ति कर्मभिः कर्मशालिनाम् ।
शुभाशुभैः शरत्काले सस्यानीव फलार्थिनाम् ॥

V i (ii) 149.8.



Milk (पय:)

दुनिचेदूदीतो भवता

मांदेसामर्थे ईदूराह।

नवल्वा दुवोयमधीतो

देसीलेवा ममले ह पमह।।

servants.' It is, howe

this special meaning in

ĀYUKTAKA-- A technical offic


expression 'Āyukta-puruṣ

BALĀDHIKṚTA-- A technical m

शाखा Śākhā

किन्तृष्णामहाशाखे चित्तस्थाणौ स्थितिं गते ।
एकरूपतया धैर्यं प्रयाति शतशाखताम् ॥ V. 21. 23.

त्समूलं परित्यक्तं तत्यक्तमिति कथ्यते ।
मूलकाष्ठस्त्यागो यः स शाखालवनोपमः ।। V.(ii) 3.31.



शाखा

भुजशाखाढ्यं पूरिताकाशकोटरम् ।
द्ररूपमिवोन्नृत्तं चन्द्रार्ककृतकुण्डलम् ॥ IV.49.13.

1. आतप.

द्वाविंशतिस्त्रिलोकी ... यथालयः।
प्रतिपद्यते ... प्रोदितः
... ।।

VI (i) 25-48.

subjective.[1] It is an in

together the series of ac

moment, day

श्री रहे


together the series of ...
moment ...

नलिनी मर्दिता सैव समं तेन स षट्पदः ।
गतो दन्तान्तरं व्रीहिरिव चूर्णत्वमाययौ ॥ VI (i) 62.26.

together the series of ...

moment, d...

সামনা (আবরণ)



पुंस्कोकिलसमालापा माधवा इव माधवः ।
कल्लोलबहुलावर्तौ व्यामोहमकरालयम् ।। V:(ii) 98.12

7

ठाढि.

7

सत्वा वृत्तो न्नतकुचस्फुरदङ्गयष्टिः ।
सुव्या.नवेष्टितमहो तन्पद्मपोठा


पत्रीकृता चन्नमहाभुवनोदरी व ।। VL (i) 56.85.

चितैर्भीरोचबोजस्य जगदाख्या चमत्कृति:
स्थता सौषुप्तसौम्यान्त: शिलान्त: संनिवेशवत् ॥ V.(ii) 46.5.


Marica as उपांग

कथमास्तां वद प्राज्ञ चिन्मात्रं चेतनं विना ।
कथमास्तां वद प्राज्ञ परित्वं तिक्ततां विना ।। VI (ii) 82.7

शाकद्वीप



विचित्रवर्णा विगुणा शून्ये च विततकृतिः ।
जडस्पन्दोत्पातमयी शक्रचापलतेव खे ॥ Vi (ii) 160. 18.



Candrabimba, ~~[illegible]~~. Candri

Induśrī - Indulakṣmī - Induka

Śáśāṅka

अथ तं द्रष्टुमायान्ति सौहार्देनैव राघव: ।
पूपाविवोदितं चन्द्रं विस्मयोत्फुल्ललोचना: ।। VI (ii) 47.

त्वया तस्मिस्तपस्यैव दु:खे दृष्टप्रमोदिते ।
ग्राह्यैकपावना वद्रा जनेन्द्रौ शशिनौ यथा ॥ V.i.190.20

दुष्पस्त्वालोकयन्नेव तत्क्रिया: सञ्चिपत: स्वयम् ।
बासने लोककार्येषु स्वस्यन्दन इवांशुमान् ॥ Vi. ii, 7 2.21

पेशलं वानुरूपं च व्यवहारमकृत्रिमम्

लोचनयोराह्लादनं घटे चन्द्रबिम्बमिवामृतम् ।। VI (ii) 47.

हिमशीतावदातादृगो ज्योत्स्नाप्रसरहासिनी ।
पूर्णेन्दुश्रीरिवोद्युक्ता दृष्ट्वाह्लादयत्यलम् ॥ Viii, 106.54.

स्मयमानमुख। ''' ... .

भार्यावरौ समं तुष्टौ करौ तत्यजतुः क्रमात् ।
स्मयमानमुखौ कान्तौ चन्द्राविव नवोदितौ ।। Viii 106.60

परिपूर्णसमस्ताङ्गः कुम्भाद्गर्भों विनिर्ययौ ।
इन्दुः पूर्वमादिवाम्भोधेरपरः कायवर्जितः ॥ Vi(i) 86.14.

दिनैः कतिपयैरेव वृद्धिमप्याजगाम सः ।
अप्रमेयाद्‌गसौन्दर्यः शुक्लपक्षे शशी यथा ।।   Vi.v.i. 86.15.

तेनाराजत पुत्रेण मुनिना मुनिनायकः ।
रत्नादौ प्रतिबिम्बेन संध्योदित इवोद्दूरात् ॥ V. ii, 86.18.


तत्र मासाद्गतौ वृद्धिं पुनिमन्दाहुतिक्रम: ।
वपृताक्वौ शुभौ गर्भं इन्दोरिन्दुरिवानुज: ।। Vāyu 86.12

इच्छानिच्छात्मिके शक्ती येतरापि त्वमेव च ।
न हंशुव्यतिरेकेण शशाङ्क उपलभ्यते ।। VI (i) 100. 34.

मणिमार्गे स्थितप्रायं हस्तप्राप्यं ददर्श सः ।
मेरावुदयशृङ्गस्थो मुनिरिन्दुमिवोदितम् ।। V. 10. 88.6.

नैन सा चित्रभूर्मीनि सप्रकाशा विकासिनी ।
भवत्यालोकरम्या च सं यथाभिनवेन्दुना ।। V.(?) 44.17.

सं



मेरो ललिताक विभागीका
श्री म परम चाल्नेमा ।
पारि पूर्णे ठुलाद स्वेष
जनसामरशे रघुवद्दा ॥
V.i.112.15.



[illegible]
[illegible] ।
[illegible]
[illegible] ॥

Viu 4. 2



पश्चात्सुगर्भमसि नवार्णवमूर्ध्नि भासा

सौवर्णपर्वतशताग्रशिखाः कचन्ति ।

(सौवर्णपर्वतशताग्रशिखा।(कचन्ति

संध्यारुणा उदयनास्तमयावनीनां

स्तोकोदितेन्दुकलिका इव दिङ्मुखेषु ।। VI (ii) ।

प्रदा्ख्याद्कदेहस्याविसंवादेन संविदः ।
अन्तः पूर्णस्य वदने श्रीरिन्दोरिव लक्ष्यते ॥ V. 70. 2.

सुषुप्तस्थो महातेजाः पूर्णः पूर्णेन्दुबिम्बवत् ।
समः सर्वास्ववस्थासु भवत्यद्रिर्यथर्तुषु ।। V. 70.23.

दशापाशाच सौषुप्तौं स्वचित्ते च विवासनः ।
अन्तः शीतलतामेति ज्ञो रसेन यथा शशी ।। V.70.22

विगतपानमदा मुदिताशया: ।

शरदुपोढशशाङ्कसमत्विष: ।

प्रकृतसंव्यवहारविहारिण-

स्त्विह सुखं विहरन्ति महाधिय: ।। V. Pr. 19

न तथेन्दुः सुखयति कण्ठलग्नो ऽपि राघव ।
नैराश्यं सुखयत्यन्तर्यथा सकलशीतलम् ॥ V. 75. 41.

व्यतिरेक

स्वादनी सर्वशालीनां दीपिका सर्वतेजसाम् ।
कलना सर्वकामानामन्तश्शिवचूचन्द्रकोदिता ॥ V.78.5-20

तस्मिन्नन्तर्हिते देवे दाणात्सान्ध्य इवाम्बुजे ।
पूर्णकामः कुमारो सौ पूर्णेन्दुरिव बाबभौ ॥ IV. 48. 42.

पञ्चोन्मुखैः प्रतिस्कन्धमाश्रितैश्चमरैः सितैः ।
पूर्णं मुहुर्दृष्टनष्टैः संवत्सरमिवेन्दुभिः ॥ IV. 49.8.

[illegible] ॥
[illegible] ।

शनैरास्तीर्णपुष्पेषु कीर्णकर्पूरमुष्टिषु ।
दीर्घेन्दुबिम्बरम्येषु तस्थुस्तल्पेषु राघवाः ।। V. 2. 11.

जडेन पूर्वेनान्धेन निहतो मनसापि यः ।
मन्ये स दह्यते मूढः पूर्णचन्द्रमरीचिभिः ॥ V.13.103.


हेयोपादेयकलने क्षीणो यावन्न चेतसः ।
न तावत्समता भाति साभ्रे व्योम्नीव चन्द्रिका ॥ V. 13. 23.

प्रज्ञा बलबृहन्मूलः काले सत्कार्यपादपः ।
फलं फलत्यतिस्वादु भासो बिम्बमिवैन्दवम् ॥ V. 12. 25.

[illegible] II [illegible]

[illegible]: [illegible] I

किंत्वं भगवन्स्फारः संशयो मे हृदि स्थितः ।
तं त्वं छिन्धि गिरा ब्रह्मन्दीप्त्यैन्दुर्यथा तमः ।। (IV 57.5-



नीता विलसितोल्लासैः पुष्पकेसरधूलिभिः ।
आबद्धमण्डलाभोगं पूर्णेन्दुमिव दीप्तिभिः ॥ IV. 49. 5

पश्यैमान्यङ्ग जायन्ते स्वाङ्गेभ्यो वृन्तपुष्पवत् ।
पश्यायं स्वयमेवाद्य चन्द्रांशुकरशोभनः ॥

Vi Ui/105.38

येनैतन्मुनिना प्रोक्त मिन्दूदयशुभं वच: ।
सो यं पश्य मुनिश्रेष्ठस्तव पार्श्वे व्यवस्थिता: ।।

Vi(ii) 150.3.

क्रमान्मुनिरुवाचाथ तां यथाप्रस्तुतां कथाम् ।

शशीवामृतमाह्लादमुद्गिरन्मुखदीप्तिभिः ॥ Vi (ii) 160. 5. 102

चिद्रूपजडरूपाभ्यामाभ्यां व्येयं जगत्स्थितिः ।
जलामृताभ्यां मिश्राभ्यां शीता तनुरिवैन्दवी ॥ Vi. ii, 81.102

पश्यासृगम्भसि नवार्णवमूर्ध्नि भासा

सौवर्णपर्वतशताग्रशिखाः कचन्ति ।

(सौवर्णपर्वतशताग्रशिखा।((कचन्ति

संध्यारुणा उदयनास्तमयावनीनां

स्तोकोदितेन्दुकलिका इव दिद्मुखेषु ॥

Vi (ii) 134.56.

मेरु हेमतटोत्तोत्पूर्णेन्दुमिव चंचलम् ।
तमालोक्य द्विजसुतं समुत्तस्थौ शिखिध्वजः ॥ Vi vi 85.65.

अविचारवतो दृश्यभ्रान्तिर्गगनमय्यपि ।
जातैव पारिकद्वीन्दुदोषवन्नोपशाम्यति ॥ Vi (ii) 164.17

द्वितीय इव शीतांशुर्द्वितीय इव भास्करः ।
द्वितीय इव वौर्वाग्निश्चन्द्रार्कस्पर्धयोत्थितः ॥

V; (ii) 155. 29.

तत्र कान्त्युति मुखं चकाराखिन्नमानसा ।
इन्दुं मनोहारमिव श्यामा खिन्नमिवाम्बुजम् ।। VI (i) 104.35.

तत्याज दयितां सुप्तामङ्कादाजा शिखिध्वज: ।
स्वैरं स्वैरं मुखं राहोर्दिशंक चान्द्रप्रभामिव ।। V(i)84.44

चन्द्रबिम्बकलापूरमेकत्रैवोपसंहृतम् ।
स्त्रैणमालोक्य तत्कान्तं सहसैव मनो मुनेः ।। Vi (i) 85.101.

केप्रानि निर्व इन्याति
रव रो पु म धुरेषु न।
राणि ते पु रति रामं
प कोषिनेव निश्चाकर॥
V. ९३. २१.

Vaiṣṇava faith in ...

which qualifies 'bappa',

titles of 'Parama-bhaṭṭār

which qualify it, show th

one of noble or regal bir

~~ति ष्ठित्यस्खे दोदयमत्तहर्षं~~

निम्नु,ाप्य सामाज्य महापदेवा

सरीलद्पलं सुरना यतो वा ||

ति ष्ठत्यस्खे दोदयमत्ता हर्षं

दाखोदये | विन्दु रविन्दरस्य ||

५.१३.१९.

ional na

alphabet. (Dewal In

upright strokes, wi

'crooked, curved, o

LĀÑCHANA-- A crest as dist

मैत्र्यादयोऽथ मुदिताः
शरशाद् इव दीप्यते ।
जीवन्मुक्तमनोनाशे
सर्वत्र सर्वदा स्थिताः ॥
V-90.21.

gives a much more

of all objects in

account of the fac

"In the begi

सैषूजिता सखीयुक्ता गणमण्डलिका तथा।
पूजान्ते पूर्णशीतांशुरश्मिरशीतलया गिरा॥

6·29·103.

t mill. The economy was also

to the present day. How was it that

e menance. Were they mere spectators

eing enacted before their very eyes

ng to alleviate the distress. What

दमयन्ती तौ तु वारवृदं
स्रोमं स्रोमाद्विशोखरे ॥
पुंलवानां ददृशातु:
कुमुदे शगशिनं यथा।
प. ८६. 12-13.

grain. Moniear Williams notes it in
only.

s or infamous lady or an unfortunate

Moniear Williams notes it in

तौ ता प्र ऐम्न दैवे तुखार —
मल भी श्वरम् ॥
स्वावा प्राधि जावु बितं
पारिपूर्ण निवेदनम् ५
ला ८६.१३-५५

: : -

y of coins. Monier William notes it in
only.

maiden.

चन्द्रबिम्बोपमाकारा दारा इव गुणाकरा: ।
यश: पुष्पामन्दिशो भाविसत्फलहेतव: ।। Vi (ii) 78.11

: : -

y of coins. Monier William notes it in ,
only.

अक्षमालाधरः शान्तो हेमयज्ञोपवीतवान् ।
अग्निशौचाम्बरच्छन्नः सद्यश्चन्द्र इवोदितः ।। V:(?)130.21

: : -

y of coins. Monier William notes it in
only.

त्रिभुवनहाट्टहासो

भुवनमहाभवन एष मद्कौन: ।

दारिरसलिलावपूरो

गगनाब्धेश्चान्द्र आलोक: ॥ V(ii) 115.43.

: : -

y of coins. Monier William notes it a

शीतता या न शीतांशोर्न हिमाचलकन्दरे ।

न रम्भाचन्दनावल्यां निःस्पृहेषु मनः सु या ।। VI.21.17.

अतिरेक

: : -

y of coins. Monier William

अमृतापूरितः स्वस्थः शीतलात्मा महाद्युतिः ।
तिष्ठाम्यानन्दवानन्तः सायं पर्ण इवोद्दुरात् ।। V. 22. 45

अथवा रघुवंशाख्यनभः पूर्णनिशाकर ।

बन्निबदुद्धिभेदेन ज्ञानमासादयामलम् ॥ V. 22.1.

पत्राला घनसंघाता: सच्छायावृतभूभृत: ।
गुणानां महतां योग्यता वंशा वंशा इवोन्नता: ।। Vi (ii) 120.13.

देहेष्वाजरणं सवीरसानां पवनो न्वहम् ।


जनयत्यग्निमन्योन्यसंघर्षादिव वेणुवत् ।। Vi.iii 81.70.

तेन क्ष्मापतिनेत्युक्ते कुम्भ आहासने विशन् ।
गिरा विषण्णाया शीर्णवंशस्वनसमानया ।। VI (i) 104.39.

उच्चकैः सुप्रमाणेन निर्मितैः कुसुमैः समैः ।

दोर्घेन्दुबिम्बप्रतिमैस्तुषारस्थलशीतलैः ।। Vi (ii 106. 6

যমুনা



आययौ यामिनी श्यामा भुवनं धम्मधूसरम् ।
कृत्व्योमापगां सर्वां संश्लेषा यमुनेव सा ॥ V (i) 84

Bamboo (Vaṁśa)



Creeper as an Upamāna.

कोकिलाकुसुमापूरननां वनलतामिव ।
का त्वमुत्पलपत्रादिदा कान्तिविदोपितम्बरा ॥ IV. 57.10.

अभ्यस्तेना स्तोतिकन्नां पद्कृत्वा पृदों ननामिव ।
शेषं तु वदसंस्थानस्तिष्ठाम्यचक्रमद्गवत् ॥ V. 86. 4.

अस्तित्वस्तोत्रिकान्नां पदकृत्वा पूर्वोक्ताविव ।
शेषं तु बद्धसंस्थानस्निष्ठाभ्यन्तरमृद्गवत् ॥ V. 86. 4.

लमोवि शतलतमेतां
पुरुहौ ह्रदय ङ्मे।
इलाना किशमानि लानानि
पातैं शिर्वविदेव लासिद्धदेवै।
V: vi, 11. 6.

रत्नपुष्पभरापूर्णरिक्तपल्लवपाणयः ।
भवन्तं पूजयन्तीव लतादारान्विता द्रुमाः ॥ Vi (ii) ((S 68.7

लेता > दारा

सर्वा हि वासनाभावे प्रयान्त्यफलतां क्रियाः ।
अशुभाः फलवन्त्योपि सेकाभावे लता इव ।। V. (ii) 87-19.

न स्वभावेन फलति यथा शरलता फलम् ।

क्रिया निर्वासना पुत्र फलं फलति नो तथा ॥ V.(?) 87.21

ताकारभासुराप्युच्चैर्न ददाति फलं क्रिया ।
शुभाशुभा वा तज्ज्ञस्य फुल्ला शरल्ता यथा ।। V(ii) 87.23

।विचरद्धियमप्रौढां
हरन्ति विकसद्रमः ।
प्रचण्डपवना मूढीं
वृन्तावृन्तां लतामिव ॥
५.१३.१२

or its site. Also call
which Buddha and his pr
perfect wisdom.(no.71).

BOPPA-- A Prākrta word for

CAKRAVARTIN-- A title of p
IV. the first of the f

[illegible]

[illegible]

[illegible]

xxxxxxxx agriculturist
bed by the march of arm
molesting cultivator wa

तृष्णाकरञ्जलतिकामिमां
हृदि मुपागताम् । सङ्कल्पमूलो
द्धरणात्पादिशोधवती कुरु ॥
6.(i) 33.44.

युग के प्रतिनिधि सा

गया है । भारत के स्व

प्रभावित हो रही थी

तीर्थस्थानों का वर्णन

रचना काव्यमय हो उठ

कवि बन जाता है, उस

क्रमादृतूनि सर्वाणि सरसानि चकाशिरे ।
तस्य पुष्पाकर इव लताजालानि भूभृतः ॥

III. 58. 38.

M.Bh.only.

ine or bodily pain. M.W.notes it in

only.

dly it means discharged, undressed,

or dressed etc. but the author has

in a strange sense viz. "captu-

रुपलक्ता मु. शेवाळा
ललालूना नोविची
प्रा. ८९.१२

...amana III.39. (1) Per(
lex? u

XXXXXXXX (2) Hear'p

Niska II.3 XXXXXXXXX Gold. Nc AT

Nodyam II.31. Wonder. [uo

Peksin II.41. a day witour
William n

Pancasikha II.34

स्वर्ष्विमेव विकसत्स्वङ्गना विबवलाकरी।
अतस्य हृदि सादरं भाविव पेलव वल्लवा॥

VI (i) 6-41.

Nisamana III.39. (1) Perc
lexi

d Vivrti II. 11. 6,
.V.T.T., p. 280, etc.

अहंकारोपहतया बुद्ध्या या क्रियते क्रिया।
विषवल्ल्या इव फलं तस्याः स्यान्मरणा-
त्मकम् ॥

VI (i) 29-49.

...s their development or decay. When an
...ysical peculiarities different from
...contrast inevitably points to a differ-
... time is inferred as the cause of it.
...ing substances are supposed to be in
... for on no other hypothesis can change

N1 samana III.39. (1) Perc
lexi

उत्तिष्ठ तात गच्छामः पश्यामो मन्दरस्थिताम् ।
तां तनुं तावदाशुष्कां शुष्कां वनलतामिव ॥ IV.14.44.

१

s contrast inevitably points to a differ-
nd time is inferred as the cause of it.
nging substances are supposed to be in
, for on no other hypothesis can change

सर्वाशाः किल संत्यज्य फलमेतदवाप्यते ।

नैराश्यविषवल्लीनां मूलमाला विलूयते ॥ V. 8. 15.

nging substances are supposed to be in

, for on no other hypothesis can change

शास्त्रसज्जनसंसर्गैः प्रज्ञां पूर्वं विवर्धयेत् ।
सेकसंरक्षणारम्भैः फलप्राप्तौ लतामिव ।। V. 12. 24.

nging substances are supposed to be in

, for on no other hypothesis can change

लता नागेन्द्रमृदिता धारयन्ति न संपदः ।
पुत्रिका रक्तपांसस्य कान्तेयमिति सादरम् ।। IV. 59.8

nging substances are supposed to be in
, for on no other hypothesis can change

संपश्यद्राजतां स्वप्ने ककुब्वनयपाञ्चिनीम् ।
लाञ्चितां भोगपूगेन पुष्पौघेण लतामिव ।। VL (i) 62.13.

... it.

nging substances are supposed to be in

, for on no other hypothesis can change

सुविरागचमत्कारविचारकणिकोद्भूत ।

वयस्यपि च तारुण्ये दैवाद्दत्तो मराविव ॥ V. ii. 74.14.

nging substances are supposed to be in

, for on no other hypothesis can change

यस्य दृष्टिदृढाघातनुन्नाधारकुलाचलाः ।
विनमन्ति दिशः सर्वा लताः फलनता इव ॥ V.22.23.

, for on no other hypothesis can charge


कृपादभ्यस्यमानैषा विषयारतिरात्मज ।
सर्वत: स्फुटतामेति पेशलिका लता यथा ।। V. 24. 20

वसन्तरसपूरस्य यथा विटपगुल्मता ।
स्वरूपमात्रमरितसंविदः सर्गता तथा ।। V(ni) 43.11

यथाहं तरुणी जाता समुद्भिन्नोन्नतस्तनीं ।
ततोत्पलहुलुच्छेव विलासरसशालिनी ॥ VI (ii) 64.56.

ा दिवैतना सा विरसा बभूव परिजर्जरा ।
ा मार्गशीर्षान्तवल्लीव जराविधुरतां गता ।। VI (ii) 71. 8.


कण्टकद्रुमवल्लीव करालकुटिला मतिः ।
आयुरायाबशान्तिव्या यामिन्येव तमोन्धया ।। V. (ii) 25.9



चमत्कृतिश्चेतसि या दृढा सैव विजृम्भते ।
वल्लो त्यजन्ति नैदाघो पीतमप्यम्बु माधवम् ।। VL (i) 63.12.

उत्तार्यौ किंचिदाम्लानवदना खेदशालिनी ।
कुसिकैव महावल्ली निरुत्साहांगपल्लवा ॥ V.iii. 85.4.

४ ।
यान्येतानि दुरन्तानि दुर्जराण्युन्नतानि च ।
तृष्णावल्ल्याः फलानीह तानि दुःखानि राघव ॥ V.15.7



नीरसा एव ते सन्तु समस्तेन्द्रियसंविदः ।

आकारमात्रसंलक्ष्या हेमन्तर्तौ लता इव ॥ V. [illegible] 1. 19.

अन्त: पुरमदृश्यैव विवेश ललनाकुलम् ।

मधुमासमहानद्यो नैसल्लस्तमिव द्रुमम् । VI (i) 104.33.

प्रावृषीव लतातुम्बी तृष्णिका दीर्घतां गता ।
शैलनद्या रय इव संप्रयात्येव यौवनम् ॥ VI.i.78.5.

चित्तवृत्तिगता यस्य तालोत्तालमनोवने ।

फलिता सुखदु:खाभ्यां मरणं तस्य राजते ॥ V. 39.41.

वासनान्तिका प्रावृणनदो नदगता यथा ।

एकान्तरत एकात्मा नीरसः शान्तवासनः ॥ V. ci. 85. 38.

बभूव तस्य हृष्टस्य मदनस्खलितं तदा ।
फलं रसापूर्णमिव ग्रीष्मान्त इव तयोर्यद: ॥ V.(i) 85.103.

सुहृद्यावेदितं दुःखंधर भायाति तानवं
घनं जडं कृष्णमपि मुक्तवृष्टिरिवाम्बुदः ।। (VI (i) 105. 3
सुहृदा पृच्छता साधु चेतो याति प्रसन्नताम् ।। ~~VI (i) 105.~~

स्वच्छतोपगतेनाशु कतकेन जलं यथा ।। VI (i) 105. 4
~~अहं तावदितो यातो भवते पुष्पमंजरीम् ।~~

सा चिदत्यन्तविमला जगदर्थं जगत्क्रियाम्।
उमा स्त्रायति प्राज्ञ रसेनैव मधुर्लताम्।

6·30·27.

. Trees and forests help in more
nd forests there are less chances of
e greater extent of forests did provide
ry food supply in the form of edible
es. If in spite of so many checks and

एवं जगत्त्वमहमित्यवबोधरूप-

मायासमात्रमुदितं न च नोदितं च ।

अर्कांशुजालरचनामृगवारिमत्र

मुह्यादि सत्यमिदमस्ति न सर्वे नैव ॥ Vc, २.१२

greater extent of forests did provide
y food supply in the form of edible
s. If in spite of so many checks and
e. the st

आन्तो नां तां निवेदयामि बालां भुजलतानुगाम् ।

मृणालहारकुन्देन्दुवृन्दवलयभिनाभिषणी ॥ V(i)77.27.

greater extent of forests did provide
y food supply in the form of edible
es. If in spite of so many checks and
e, the state

इदं तु शृणु वक्ष्यामि यथाभूतमनिन्दितम् ।
यथैति तनुतां चिन्ना मार्गशोधिन्तेव ते ॥ V 49.22

greater extent of forests did provide
y food supply in the form of edible
es. If in

अन्तशून्या ग्रन्थिमती श्लक्ष्णा स्वांकुरकण्टका ।
जडा रसमयी दीर्घा लतेव वनवेणवी ॥ Vi (ii) 160.14.

greater extent of forests did provide
y food supply in the form of edible
s. If in spite of so many checks and
e, the stat

Bank (Tira) Tața

) greater ex[illegible]

दूरात्तावद्विक्लिन्नमनुसस्रुर्वेलानि ते ।
यावत्तीरं समुद्राणां प्रवाहाः सरितामिव ।। Vi(ii) 113.3

greater ext... ... ...uld provide
y food supply in the form of edible
s. If in spite of so many checks and
e the Stat...

तरवरळ्पातङ्गतरङ्गौघविघट्टिताः ।
अत्यजन्तो निजं धैर्यं वेलावरतटा इव ॥ V(ii) 122.14.

greater ex... ...ld provide
y food supply in the form of edible
es. If in spite of so many checks and
e, the Stat...

Cloud as standard of comparision

supply in

मुग्धमुग्धकचंत्कान्ति हेममन्दिरसुन्दरम् ।
उत्फुल्लकिंशुकाकारं संध्याम्बुदवदुत्थितम् ।। Vi.ii.130.8.


supply in

ततो बभूव सा रक्तपरिपीनशरीरिणी ।

रक्ता वर्षाभ्रमालेव तडिच्चलल्लोचना ।। Vi(ii) 134.18

supply in

तत्रोपविष्टास्ते देवा ळदयन्ते शृङ्गमूर्धसु ।
सुशुद्धकान्तयस्तापादजला जलदा इव ॥ Vi (ii) 134. 41.



स पश्यत्स्वेव सभ्येषु मृगो थ नरतामगात् ।

ज्वालोदरे नभस्यभ्रलवो रूपान्तरं यथा ॥ V(ii) 130.15

तटस्थितैर्यां विददृश्यमावं

शरन्नभोमेघलवा इवापुः ।। V:(i)/122.6.

सर्गे स्फुरद्भिर्मत्पुण्यैर्मन्त्र्यै संप्रेषितो भवान् ।
अलक्ष्यैः संभृतैरद्रौ बृहद्वातैरिवाम्बुदः ॥ U. i. (i) 87.1

प्रतनोति शष्पच्छायां छायामिव घनागमः ।
निरोधमास्फारयति शमो निज इवाम्बुदम् ।। Vi (ii) 55.28

पुष्पांजलिं जहौ व्योम वृजन्कुसुमदामजम् ।
विसारि वनवातेन हिमं हैम इवाम्बुद: ।। VI (i) 104 29.

संपद: प्रमदाश्चैव तरङ्गा भोगभङ्गुरा: ।
एतान्त्यशनयस्तस्मिन्दुष्कृताभ्रसमोरिता: ।। V. (ii) 45.14.

शीतलास्पर्शवत्स्निग्धाः प्रावृषीव पयोधराः ।

भूभृद्भङ्गंकरं घोरा देशभङ्गदमाकुलम् ॥ V (ii) १४.१.

तानि वद्य सहस्राणि जग्राह भुजमण्डले ।
धारा निकर जालानि मेघमालेव

कोटरे ॥

III . 82.55.

- 3 -

shed clothes.

knife for a dagger. Monier Williams notes
ie lexicons only.

, ripened. Monier Williams notes in
s only.

. Monier Williams notes it in lexicons

only.

[illegible]

[illegible] ॥

[illegible] मुने [illegible]

[illegible] ॥

[illegible]

प्रपारिशुमिताधारा:
सभासां वायसा: स्थिता:।
विशेष सेवा वातेन
समेने वाप सारितादृ।
V (1) 15. 26-27

[illegible]

[illegible]

[illegible]

[illegible]

Vi (i) 11. 87.

पुंस एवम् अदृष्टस्यते
न शुद्धेन न दृष्टः।
स्वाङ्गुष्ठ चर रमाय:
पाद दीन कमारः॥
V.i.17.1.

[illegible]

[illegible]

[illegible]

[illegible] ||

V. 89. 8.

... settled in the

ere Kuṣāṇas whom Chandragupta II

ura insc. corroborates this (No.32).

explanation.(No.80).

of the tribe governing it. Vākāṭakas

in literature, nor in the geneologies of

ayaswal identified the name with a villa

tate near Jhansi, the link between this

dynasty being the 'Gotra' Viṣṇuvṛddha of

इ त्री य स मा त्रिला इ द य

[illegible]

[illegible]

[illegible]

V. 10. 27.

[illegible]
[illegible] ।
[illegible]
[illegible] ॥

V. (?) 6. 15.

कान्तालताहस्नदनचारुचामरमं जरी ।
धनुर्निसेव विदाुव्यवरवारणमण्डला ।। V. 1. 26.

विभान्ति वृष्टयस्तस्या धर्माणि जलजान्विका: ।
इव नीहारहारिण्या नीलवारिदवासस: ।। VI (ii) 81.59.

शुभ्राभ्रशतसंकाशं चन्द्रबिम्ब गणोपमम्।
प्रकटीकृतदिकुण्डं तदालोक्य मया स्मयात्।

6·29·95

wantxonx agriculturist
bed by the march of ar
molesting cultivator wa
How vigilently the old
the agriculturist from
efficiency

सदा सिपाहिपनसे रहियो

स्वराज्यका सिपाही बनके।

सदा पथ्य रखना चाहिये

सिपा नशेबाजी न करे॥

८.११.३८

-raphica Indica

-to History
- Inscriptions

-History of Indian
-Literature

-on, Inscriptions

-rnal of the Bihar and
-a Research Society

कृशा बहूपवासैव परिनिम्नमहातनुः ।

कज्जलश्यामला मेघमालेव पवनाकुला ।। VI (ii) 81. 11.

परमाणुरथो भूत्वा ततस्त्वन्तर्द्धिमाययौ ।

इत्यसौ शममायातः शरदम्बुदखण्डवत् ॥ VI (ii) 86.8.

कलधौतमयो स्फारा संध्याजलदसुन्दरो ।
ततो हं विस्मयाविष्टः प्रविचारितवान्पुनः ॥ VI (ii) 86.17.

प्राणेनाकृष्यमाणं तद्भक्तं भगवतीमुखे ।
अविशत्सांध्यमेघौघ इव मेरोर्गुहान्तरम् ।। V. (ii) 134. 16.

इत्युक्त्वा स समुत्तस्थावविदद्व्यथितः शमी ।
विष्टरादवदातात्मा शृङ्गादिव शरद्धनः ॥ V.ii/92.20

चतुरायुधधाराग्रचूर्णीनोहारधारिणः ।
विद्युद्वल्लयिनो वाता वैल्लितायुधवारिदाः ।। Vi (ii) 112.4.

प्रपन्तौ वो विष्टुशेषु पकैपाः करोत्कटैः ।
हरन्ति वो कराम्भोदा मेघानुदाविता इव।। VI (ii) 114.13.

विविधप्राणिसंपूर्णैः सजलाद्रिवनोन्नताः ।
यथैवाम्भोधयः सर्वास्तथैव द्वीपभूमयः ॥ Vi (ii) 114.15.

मूततण्डुलमांसृष्टैः पिनष्टि घुवकोलकः ।

नियत्या वन्निती रौदः कपाटाम्भौदघर्घरः ।। VI (ii) 66.12

सम्यग्ज्ञानेन भूतानि ज्ञस्य देहतया सह ।
पीठबन्धं विमुंचन्ति गतकाल इवाम्बुदाः ।। VI (ii) 51. 22.

—

उपर्यंस्थगयद्वाल्लतौघेन स तं शठः ।
शून्यतातन्तुजालेन शरत्काल इवाम्बरम् ॥ Vicci/88.24.

अनन्तरं सभामध्याद्रातंदीप इवाहत: ।
ज्वालाजालं ययौ क्वापि संध्याम्बुद इवाम्बरात् ॥

V i (ii) 130. 17.

आ दोनतां

आगन्तव्यं त्वया शीघ्रमेवं वदति भूपतौ ।

पुप्लुवे थ वनाद्योम् शरन्मुखपयोदवत् ।। VI (i) 104.28

दृश्यमानमपि दाामं शरदोवाप्रचण्डलम् ।

चितचित्रकृताश्चित्रै संस्थिताश्चित्रपुत्रिका: ॥ VI (i) 56.15.

ष्य।.

पातालतो भूतलतो थ दिग्भ्यो
ज्वाला विनिर्गन्तुमनुप्रवृत्ताः ।
संध्याभ्रवच्चाशु बभूव विश्वं
ज्वालामयं मण्डलमेकमेव ।। V(ii)140.63.

भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते ।
विच्छिन्नशरदभ्रांशविलयं प्रविलीयते ॥ V.(i) 126.61

स्फुरत्यहंकारघने हृदयोऽस्मिन् मलिनात्मनि ।
विकसत्यभितः कायकदम्बे दोषमञ्जरी ॥ V 53.28.


अपूर्वमेतदाख्यानं ममापरभयप्रद ।
कथयापनयास्माकं हृद्व्योम्नः संशयाम्बुदम् ।। V.23.12.

एतेन राघव विवेकपदेन शान्ति-

पाशादयोदयवता मनसा विहर्तुम्।

मा दीनतां व्रजतु रागमयो मतिस्ते

दोणा दणादमलिनेव शरदनालो ।। VI (ii) 26.42



आमोद, सुरभि, गन्ध

fragrance as an upamāna.



धारणां संविदा बद्ध्वा प्रदेशं स्वं तमत्यजम् ।
तत्प्राणैः सह निर्याति आमोदः कुसुमादिव ।।

प्रवृत्ति निवृत्ति लेलक्ष्य
लुहतरेन पदे पदे।
निरनुरूपने नन्दा
दामोदर कुसमा चिन ॥
नादरनरानि पदपो
ईनाईरडन सिवानाद।

प्रवृत्तिनिमित्तस्य
दृष्टतरेण पदे पदे।
विनिवृत्तरच्यते वन्दा-
दामोदरः हृष्टमान्दिन ॥
तन्ववरचनि पदसो
दुर्भाईरद्वन्द्विलात्।
देहदग्गलनरि अनोगी०२०१

वैकामोदसर्वस्वं चेतः कुसुमकोशतः ।
वा मूर्च्छां प्रयच्छन्ति विषया विषवायवः ।। V.C (2.1) 93.67,

ायैं सर्वगतो जीवः स्वामोदः कुसुमे यथा ।
यथाप्योजसि किंचित्कंपुंसे शैत्यं विवस्वता ।। V:(ii)137.25
5

्णाया प्राणस्ततश्चित्ताऽन्वितो मया ।
ाद्धेचितो बाह्ये सौरभं कुसुमादिव ।। Vi (ii) 137.२.

अन्तः शीतलतामेषां तां न जानन्ति केचन ।
दूराच्चन्दनदारूणामामोदमिव जन्तवः ।। V(ii) 102.25

अस्योक्त्या छित्वैवा सूचिर्भूत्वा लब्ध्या - विश्राम्यहम् ।
प्राणिनाँ सह सर्वेषां हृदय सुरभिर्मया॥

III 69.4.

-ersity of Oxford
accept me its member.
will enable me to were
of Oxford for my
life and guidance of
w, /Bodleian Professor
ll University
ways cherished of Oxford
a visit to
-ra from there

सौरभं कुसुमासङ्गाद्देव सत्सङ्गमाच्च मम।
वर्तते ह्यर्कसंपर्काद्विकासोऽम्बुरुहेष्विव

III. 82. 7.

... already observed. Hence, previous
-existent, it could have no succession,
o prior and posterior. And even when
es exist, it can not be differentiated,
there is no succession. Succession,
s based on difference and difference...

भावाभावलसद्दोलं तेनायमवलोक्यते ।
सर्गः सदसदाभासः पूर्वगन्ध इवेच्छया ॥

III 65. 2.

(R:

विभज्यते चन्द्रादामोदः कुसुमादिव ॥

VI (i) 6 - 37

...er or force, which is kāla.

...es things, it gives rise in the percipient
... to those things, of past, present and
... That is to say, it produces all those

वेदनिरूपणाया प्राणास्ततश्चिचान्वितो मया ।
शरीराद्विचितो बाह्ये सौरभं कुसुमादिव ।।

to those things, of past, present and (20)
That is to say, it produces all those

ततो ंच: संप्रविष्टो हमामोद इव मारुतम् ।
उष्णांशुरिव शीतांशु मृत्पात्रमिव वा पय: ।। VI (ii) 157 27

to those things, of past, present and (२०)
That is to

(४१)

कार्यं सर्वंगतो जीवः स्वामोदः कुसुमे यथा ।
तथाप्योजसि किंचित्कर्मुखे शैत्यं विवस्वता ।। VI (ii) 137.25

धारणां संविदा बद्ध्वा प्रदेशं स्वं तमत्यजम् ।
तत्प्राणैः सह निर्यांत आमोदः कुसुमादिव ॥ VI (ii) 140.49.

अथ वातरथारूढो गगनं भ्रान्तवानहम् ।
पुष्पामोद इवानन्तं गत्वा च त्वरया चिरम् ॥ V | (ii) 150.28

रुद्रभूतवपुस्तत्र तनुं तत्याज तामसीं ।
गन्धः पवनतां गच्छन्कुसुमस्तबकं यथा ।। VI. (i) 63. 3.

ष्पकोश इवामोदो महोर्मिरिव सागरे ।
श्मिजालमिवादित्ये मनो ब्रह्मणि राघव ।। V(2) 114.2

संतोषामोदमधुरः सत्कार्यामलपल्लवः ।
चितनालाग्रसंलीनो विघ्नकण्टकसंकटः ॥ V.ii.126.36

रैचक्राभ्यासयोगेन जीवः कुण्डलिनीगृहात् ।
उद्धृत्य योज्यते यावदामोदः पवनादिव ।। Vi(i) 82.29.

तो च: संप्रविष्टो हमामोद इव मारुतम् ।
ष्णांशुरिव शीतांशु मृत्पात्रमिव वा पय: ।। V(ii) 37.27

परमात्ममहावायौ रजः स्फुरति चंचलम् ।
कुसुमाद्न इवामोदस्तदतदूपकं स्वतः ।। V(i)i 7R.2.

शान्ते वातपरिस्पन्दे यथा गन्धः प्रशाम्यति ।
तथा शान्ते मनःस्पन्दे शाम्यन्ति प्राणवायवः ॥ Vi/i/69.44

तिष्ठतः साधुमध्ये स्य तद्विवेककथावशात् ।
पुष्पासङ्गादिवामोदो विवेकः समुदेष्यति ।। VI (ii) 157.34.

अन्योन्यं कुसुमामोदा मिश्रिता अप्यमिश्रिताः ।
व्योमरूपास्तथा सर्गा अन्योन्यं भिन्नरूपिणः ॥ V(ii) 37. 80.

Leaf (Parṇa) as उपमान.



परस्परंनिगीर्णाङ्गा जनता जाड्यजर्जरा ।
संभ्रान्ता प्रभ्रमत्यङ्ग शीर्णपर्णमिवाम्बरे ॥ V. 68. 35.

विलासभासनामानौ वृद्धिमाययतु क्रमात् ।
नौ पित्रौः पल्लवे दोर्भ्यां लतापादपयोरिव ॥ V. 65.23.

बहुविधसुखदुःखमध्यपातो

विनतजरामरणप्रवातभग्नः ।

जगदुदरगिरौ लुठ त्यसौ यं

गतरसपर्णवदेति जर्जरत्वम् ।। V. 66. 39.

चिन्ताचक्रे चिरं बद्धं कुक्रियाचारचञ्चुरम् ।
चेतो भ्रमति सामुद्रे गर्तावर्ते तृणं यथा ॥ V. 66.33

नोरसा नि:सुखा नक्तो पतत्येनवगात्रिका । V. 66.22
जीर्णपर्णसवर्णेयं दायते दिवाभावतो ॥

न भवत्यसुसङ्गानामाशापाशविघायिनाम् ।
दग्धानामिव पर्णानां रसानां पुनरागतिः ।। V. 83.24

V. 82.12

अहो नु चञ्चलमिदं प्रत्याहृतमपि क्षणात् ।
न मनः स्थैर्यमायाति तरङ्गप्रोढपर्णवत् ।। V.82.12

पेतुः श्वा निवातान्तरे शुष्कवन-
पर्णवत् ।
नियुर्लोहिता नद्यो रणाद्रेर्भीति-
वर्षिणः ॥

III. 46. 28.

:

प्रियार्थैव प्रददामि तुभ्यम् ।
वस्तु प्रियमत्र लोके ॥ २०७ ॥

ष्टं विनष्टो रूपपथप्रविष्टः ।

अप्रकाशमानाः स्फुरन्त्येते
आरभमाणाः सहितश्च ।
नाना च दुःखानि दुःखान्तु
पादपे विविधे फलदाः ॥
III. 15. 7.

्यते कृपाविषयी क्रियते इति कृपण: one who is
se we come across many uses in
the word developes the sense of a
ncient times, as even now, looked down
sight was and still is considered
pming. He was thus a pitiable
appened in this case is th

आयान्ति चाभ्युद्यन्ते च शरीरा-
णि शरीरिणाम् । पादपानाञ्च
पर्णानि का तत्र परिदेवना?

6. (i) 32, 50 £

...lenges the
... He asserts that there is no such
e. He argues : Action that is finished
finished (or undertaken) is future, but
thing that is neither finished nor
o intermediate stage. Besides the past
there is ...

यथा जातानि जातानि
चानमानूनयानि कालत ।
वृद्धात्यपानि रमन्ते शरीरा-
णि तथा नृणाम् ॥
6.(i) 32:49.

is essay on time better than with the
losopher Kant : 'Time is a necessary
e foundation of all our intuitions. With
eral we cannot think away time from them,

स्वभाववशतो जीवो विस्मृत्या

शक्तिमृच्छतिं । वैवश्यात्मा-

लवशात: पर्णं जर्जरतामिव।।

6.(1) 32.47.

the present is perceived as associated
ure and is manifested by the continuity
e.g. in such conceptions as 'he is cook-
s series of actions 'may consist' of...

सुहृन स्नेह सर्वहृदमन

स्वभावेन शान्तमता:।

पातितौ भूतले वृक्ष

गति स्मृतावपि वल्कवौ॥

III के १०.१

rving. Monier William notes it in
.cons only.

:ing- Ibid.

mier Willa moites it in lexicons only.

h two nights enclosing it. Monier
otes it in lexicons only.

तेन धर्मप्रियां मूर्छाभाजमुत्ताढरोपितः।
ग्रीष्मदावानलोत्तप्ता नेदवः पल्लवा इव॥

III. 48. ~~75~~. 74.

writers too. Narada me
according to their util
water-courses --one cal
and the other Bandhya w
The former serves thepu
protects the field from
The latter aspect of i

ॐ उह्यमानोऽभवन्नद्या यथा जनर्दपल्लवः॥

III 19.3.

went on with his cultivation, undistur-
les and clash of arms, and as to h

गिरीनपश्यत्रभैस: पतत: पत्रपर्णवत ।
सिन्धु: सिन्धुरिवोत्पक्षान्मैनाकादी- F.
निरस्तत: ॥

III. 49.8.

authorities to meet it.
means of communication
movement of foodgrains
other could be possible
boats which necessarily

त्रपौत्रसुहृद्भृत्यबन्धुस्वजनपेटकम् ।
स्यातिविस्तीर्णमभूत्पत्रवृन्दं तरोरिव ॥ V. 47. 58.

तयत्र पत्रमिव वातविधूयमानं

नो वस्तुतां व्रजसि काचन नाम लक्ष्मी: ।। VI (ii) 157.
36.

नम: करशतैस्तस्याश्चतुरावृत्तिवर्तिभि: ।
भाति चण्डमनिलोद्धूतैराकीर्णाभिव पल्लवै: ।। VI (ii) 81. 68.

थ कालेन महता सो नुरागो विरागताम् ।
प्तौ मम शरत्कान्तौ विरस: पल्लवो यथा ।। VI (ii) 65.1.

ात्मा ह्लादयत्यन्तर्दृश्यदर्शनसंगमे ।
म्बाहूरं प्रयातस्य भित्तावपतितस्य च ॥
दिन्दोस्तैजसो रूपं तद्रूपं शुद्धसंविद: । VI (i) 48. 8.

सुधाकर सुधाधौते 7.
नीलनीरदे कलवनु।
वारसालिन्दुरवलं
सतप नाकवरम्नवरम्॥ 71.

V. (i) 18. 8



हंससो विनोनोन्नरनहंतादिदविषा ।
ोरिरपणादुदणान्न जाने कुकाशु गच्छति ।। Vi (ग)17. 7.

कस्वभावेन कालेनाकारमृच्छति ।
ासन्त: सेकाद्वीजं पल्लवतामिव ।। VI (i) 50.20

बहिर्न किंचिदप्यस्ति स्वाद्यव्युर्वोदिगादिकम् ।
एतत्सर्वं चित एवास्ति पत्रपुञ्ज इवाङ्कुरे ॥ V. 48. 49.

शरीरे कणशः कृते नास्त्यन्यद्रुधिरादिकात् ।
निर्भिन्ने कदलीस्तम्भे नास्त्यन्यत्पल्लवादृते ।। IV.35.~~35~~.24

रव: पर्णविह्यूढा मनया: पल्लवा इव ।
हिमाद्र्यो हिमकणा इवौर्व्यौ जनना इव ।। VI (ii) 81.71.

(33)

पङ्कवन्त्यप्रसन्नानि महादीपाग्यवन्ति च ।
गन्धिशँवत्तुच्छानि पत्वलानोन्द्रियाणि च ।। U.(ii) 6.47.

गघशीतवव: पत्रै सच्छाये स्मितपुष्पके ।
ाा द्भ्राम्यते राम भृशं सुजनबान्पके ।। V.64.33

ग्घशीतवच: पत्रे सच्छाये स्मितपुष्पके ।
गादिश्रम्यते राम भृशं सुजनबान्धवे ।। V. 64. 33

एव यथा जीवा वासनायन्त्रेण च ।
पर्णवदुद्दीना जडाः श्वसनवेगतः ।। VI (ii) 49.52.

न्येरुकान्तियंस्तमेवात्र ददर्श सा ।
हग कृष्णावर्णं च जीर्णपर्णमिव स्थितम् ॥ V(i) 85.47


दीर्घेण कालेन प्रस्फुरन्सर्गपणकैः ।
गमेष्यसि व्योम्नि महामहिमनि स्वयम् ॥
Vi (ii) 155. 39.

अनन्ता: पितरो यान्ति यान्त्यनन्ता
इह संसारिणां पुंसां वनपादपपर्णवत्


V. 20. 33.

Lotus as a standard of composition.

মৃণাল, পদ্ম, কমল, অব্জ, নলিনী, অম্বুজ etc.



भ्राणप्रान्तगतात्स्यात्स्वसमानौ इवेदाणौ ।
अर्धकुड्यान्तैः पद्मैः श्रियमायततुः समाम् ।। V. 84.5.



तथैव तिष्ठन्निःस्पन्दः स कायो म्लानिमाययौ ।
अन्तर्विरसतां प्राप्य मार्गशीर्षान्तपद्मवत् ॥ V. 88.3

प चत्वं गतयोः पित्रोर्दीनवक्त्रौ बभूवतुः ।
तप्ताङ्गौ विगतोत्साहौ पद्माविव जलोद्धृतौ ॥ V.65:29

अन्तश्छिकदवतो जाड्ययुक्तायुक्तगुणा स्वयम् ।
चिन्ता शोषमुपायाति हिमदग्धेव पद्मिनी ।। V. 8-3-19

विवेश रम्भारचितं निजं पर्णोटजान्तरम् ।
दृनगौरं सुसौगन्ध्यपर्णिनोलपिवौत्पलम् ॥ V. 82.7

सुमेरुकर्णिकाकान्ता सह्यकेसरशालिनी ।
पूर्णा स्फीतोदरोदेति रोदसी नलिनी पुनः ॥ IV.47.7

सुमेरुकर्णिकाकान्ता सह्यकेसरशालिनी ।
पूर्णा स्फोतोदरीदेति रोदसी नलिनी पुनः ।। IV.47.73.

त्वयगि त्वयति हे साघो सर्वा एव शुभश्रियः ।
प्रभात इव पद्मिन्यः सालोकं विलसन्त्यलम् ।। V. 83.15

तस्यैवंप्रायया तत्र ततयोदारचिन्तया ।

सा व्यतीयाय रजनी पद्मस्यैवार्ककाङ्क्षिणः ।। V. 3.1.

प्रभाततूर्यघोषेण समभिन्दुसमाननः ।
उत्तस्थौ राघवः श्रीमान्पद्मः पद्माकरादिव ।। V. 3. 3.

यस्य नेच्छा न वानिच्छा ज्ञस्य कर्मणि तिष्ठतः ।
न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः ।। IV. 46. 16.

लब्ध्वा सादात्प्रबुद्धोस्मि स्वप्नसङ्गादिवाम्बुजम्।


VI (i) 12-26.

ged that if time is supposed to posses
a relation between the property of o
ance, then there is nothing to prevent
n of qualities in substances - a
in the way of a similar capacity being
ul. Consistency of reasoning demands
ne of this capacity for producing

यथा नानैवबोध्यते
विवेकेन मनांति हि।
सततं तु प्रकाशेन
न सत्तानीव भानुना॥
III. ९९.७.

with their clear, bl
season disappears an
लाक्षणिक meaning of
this very sense the
Sutra शारदेऽतर्वे 1.
fresh. The example

हूणचीनकिरातानां मुक्तैस्तैश्चक्रवर्षिणी: ।
कमलानीव लूनानि शिरांस्यभिमुखानिवै: ।। V[illegible]


none

ताराबिन्दुयुतं देहबिन्दुभिः खं विडम्बयन् ।
दृष्टिपातोत्पलासारैः सुन्दरीः परितर्जयन् ॥

Vi (ii) 129. 49.

ततो यदृच्छयैवासौ शनैर्निद्राकुलो भवत् ।
पद्मः सायमिवापीय पयो मुक्त्वान्नमुच्छ्रमः ।। Vi (ii) 1138

अद्य ते ललने व्योम तत्परित्यज्य
न दृश्यते।
रन्ध्रैर्विशतुवातलेखेऽब्जमुकुलं
यथा॥

III 40.6

बड़े वृक्ष थे, और एक

समुद्र की ओर चली जा

बिखरी हुई आँतें कार्य

अवयव को और मरे प्र

और कंक नामक पक्षियों

भरी थी । भंवर शब्द

मैं भी युद्ध भूमि को नदी

अनुगनदी

एकस्रोत

श्रद्धे नु भगवन्तं

[illegible]

[illegible]

सूर्यसहस्रादिव [illegible] ॥

V.(1) 12. 26

विवेश सा सभां सौरव्या
वृता स्फोटस्या सिन्दला।
कमौरया सभया भोगया
रा॥ वातेन पार्थिवी॥

V.(·)2०, ll.

d, leaving the substance of the
gods and sages unharmed. After the
Manvantara or when Brahma's day
eat dissolution called Naimittika
l things come to an end by fire
only the Prākrta Creation escapes
alities and Seven Rṣis etc. At
ght lasting for a Kalpa, he awakens

ततः प्रहरमात्रेण
निद्रा मां मुक्तवाना: ।
उत्तमसुन्दरीमीक्षे
पश्चात् इव दिनानि नष्ट
V. 31. 5. 3.

RMS IN SANSKRIT INSCRIPTIONS

at,

University, Kurukshetra.

pq

- A fiscal term (No.55) meaning 'not

egular troops or by the umbrella-

s

इत्युक्ता मुनिना तेन
सा सिवैव तदा लभा।
प्रीतस्यो पद्मवदना
सविकासेव पद्मिनी॥

Vi.iii. 31.

: : -

, covetousness, bewilderment, pride an
ractice of religion.(No.35).
of the faithful', a Buddhist term.
Cf. Ottarapatha(No.1).
ses', a technical official title. see

देहेन देहवासमपि
न मन्यते येन नाहिता
समनागाति न संस्कारो
यहवतो देहसंगमः ॥
Vi. 11 6. 15.

सौराष्ट्र पर [illegible]
[illegible] ता।
[illegible]
[illegible]॥
बा. ४-५-२५

Helaraja refers to

in Karika 62 referred to

they say is itself time.

follows :-

The power called seed, w

sprout, prevents the sync

the power called sprout p

कपालपादमोदः पाटव्यम्,
नालिका नालिनी तत्वम्॥
III - 89.16

...cons only.

r williams notes it in lexicions o

anying an army. Monier Williams
xicons cnly.

er Williaims notes it in lexicons

ime half Muhruta.

Nirghosa) a parricular measure in
Williem notes it in lexicons onl

बभौ राजसमाभोगा शान्तवातेव पद्मिनी ॥

VI (i) 2-11

to be conceived as an in

of infinite duration. N

mination of time depende

condition (upādhi), as i

ततः प्रहरमात्रेण निद्रामामुद्रिताननाः ।
उत्पन्न सुन्दरीर्भीभुः पद्मा इव दिनाविनि:॥

VI (i) 1-43.

here that Nagesa bhatta, the
accept the view of the
her one, nor eternal and all-

प्रोत्सरखी पद्मवदना रविकालेव पद्मिनी ॥

ब्लि

VI (i) 1–31

a patyata nasyandante saritah sagaraya
stitasti yohyevam pasyati sopyanandhah
ananamiti trayam
gacchatiti kimucyate
dabhavanna kalpate
amarupan katham bharet
iya III. 9. 86.

मृणाले इव पत्युर्वैलूने द्वे अपि जानुनी ।
इत्युक्त्वा सा तदालोक्य भर्तुर्भावभयातुरा ॥

III. 50. 45.

Kamana. I-26.

Karsu. IV. 29. (i) Fir

(ii) A r

Br. and

Kalyan II-27. ~~Ordinar~~

the autl

in lax only

Kanda. II-10,22. An arrow

स्नेहाद्विश्वासयामास सूर्यां देवी यथाग्निजनीम् ।
अवर्धत तयोः प्रीतिरन्योन्यार्पितचेतसोः ॥ V(i) 77.37.

न रेमे लौकचर्यासु शास्त्रार्थकथनादृते ।
न जायते रतिस्तस्य दृश्ये स्थल इवाब्जिनो ॥ V. 33.12

न कदाचन पाताले दैत्या दोर्दण्डशालिनः ।
स्थिरा बभूवुरुद्विग्नाः पद्मा इव हिमाचले ॥ V. 31. 3.

पातन

क्रौंचद्वीपगिरेरेको विपश्चित्पश्चिमे तटे ।
कर्टेनाद्रितटे पिष्टः करिणा कमलं यथा ॥ VI(ii)126.3.

ततो यदृच्छयैवासौ शनैर्निद्राकुलो भवत् ।
पद्मः सायमिवापीय पयो भुक्त्वान्नमुच्छ्रमः ॥ VI (ii) 138.14

८

krams

उत्फुल्लश्वेतनलिनीनिभा नरपतेः सभाः ।
चारुचामरभृङ्गारविनानकशतावृताः ॥ VI (ii) 145. 20.

पातन—

[illegible] ៕

[illegible]

एतदालोकयसि चेत्स्वयं योगेंकसंविदा ।
तत्पश्यस्येव निःशेषं यथा करतलाम्बुजम् ।। VI(ii)150·36.

6

kram

पृथगात्मा पृथग्देहो जलपद्मपत्रवोपमो ।

ऊर्ध्वबाहुर्विरोऽन्येश न च कश्चिच्छृणोति मे ॥ V. 5-26.

रत्नांशुभिन्नापूरमुखपद्मनिरन्तरा ।
पद्मिनो वाभिनवभिन्ना नूपुरारवसारसा ॥ V. 1. 30.

चैतनैन जडा राम कल्पनोपलरूपिणी ।

पद्मनोवातपेनाशी पर्णीव प्रबोध्यते ॥ V. 13. 64.

सा तं भर्तारमासाद्य रेजे फुल्लेव पद्मिनी ।
नोलनोरजनेत्रां तां चूडालां स शिखिध्वजः ॥ VI (i) 77.36

ि ःजष्टपद्मेदाणां दोणासवैंकं स्वच्छतां गतम् ।
री निमीलिताम्भोजमिव सुप्तं दिनात्यये ॥ V. (ii) 93.7.

भूरिभावविकाराद्यो यो यं जगदुराभ्रमः ।
भुक्तमेव तद्विद्धि शिलान्तः पङ्कजादिवत् ॥ VL (i) 46.40

पद्मा: शिलान्तरिव सर्गदशास्त्वसारा

दृष्टा न देहमुपयान्ति कदाचिदेव ॥ VI (i) 46.41

यथादर्शे तथैषा चित्पिण्डाकारैर्मिता घनाम् ।
यथा पद्मः शिलाकोशादभिन्नस्तद्वपुर्मय: ॥ VI (i) 46.22.

तेन यौवनसंपन्नविलासरसशालिनी ।
तं विना व्यसनेनाहं दह्ये ग्नाविव पद्मिनी ॥ VL (ii) 64.58

अथ निष्ठाप्यहं नाथ धन्यानां धुरि धर्मत: ।

विकापि रविणोवाब्जं यत्त्वयास्म्यवलोकित: ।। V 58 24.

स्वनमाकर्ण्य चित्सत्वगुणशालिनो ।
तपस्युपयूपतैर्देहे वसन्त इव पद्मिनो ॥ VI (1) 603. 41.
शा

तमभ्युपरते शान्तं तेजः पुंजं ददर्श सः ।
शार्वरे तिमिरे शान्ते प्रातः संध्याविवाम्बुजम् ।। V.54.45.

सरामन्तदपणा सैव तथैवाथ समा क्रमौ ।
सौम्या समसमाभोगा शान्तवातेव पद्मिनी ।। VI (i) 66.

पङ्कजानि सरन्ध्राणि सुदुर्लङ्घ्यगुणानि च ।
ग्रन्थिमन्ति जडाङ्गानि मृणालानीन्द्रियाणि च ॥ Vi...

पावनोधीपबुद्धो भूत्पूर्वसंध्याम्बुजं यथा ।
मौख्यादधिगतो नाप्तः पदे दौत्यायितः स्थितः ॥ V.19.15

पाण्डुराननया म्लानं वृक्षपर्णमिवारसम् ।
शवीभूतमिवाग्लानं छिन्ननालमिवाम्बुजम् ॥ V. 44.23.

किंचिदङ्कुरिते चित्ते नेत्रे विकसनोन्मुखे ।
शनैर्बहिर्वस्तुतत्त्वस्य प्रातर्नीले यथोत्पले । V. 39.16.

प्राणापानपरामृष्टानादो विवरसंविदः ।
वातातंस्यैव पद्मस्य स्पन्दो स्य समजायत ।। V. 38.17.

;

अथ भार्या मुनेर्देहं प्राणापानविवर्जितम् ।
दृष्ट्वा विलुलितं भूमौ विनालमिव पङ्कजम् ।। V. 19. 20

सेतुमद्गगलक्षारि क्रियमाणमुखाञ्जया ।

नन्दिन्या समघर्षिण्या मायैया पादयोः श्रितम् ॥ V. 44.26.

यन्त्रोत्थहेमवृषदा सदृशाम्बुरूपं
भुव्याद्रिभीमजलवीचिशिलेरितं खे ।
व्यावर्तते दिवि दलावृतकर्णिकास्थ-
ध्यानैकनिष्ठपरमेष्ठिसरोजमेतत् ।।

पद्मकोशाङ्कुरङ्कुदा नौ ननौ नोत्पलेदाणा ।

आमोदशुमफांकारा स्थास्थिता पद्मिनीव सा ।। V:(i) 106.49

व्यवहारपरो त्युवं रागद्वेषमयो पि सन् ।
नान्तः कलङ्कमायाति पद्मो जलगतो यथा ॥ V. 64.7.

नानागृहौगृकचनं नानाकारागृपश्चिमम् ।
व्योमनोंन्सरः फुल्लताराचन्द्रार्कपङ्कजम् ।। VI (i) 56. 31.

दग्धं तु वासनाबीजं न निमज्जति वस्तुषु ।
सुखदुःखादिषु स्वच्छं पद्मपत्रमिवाम्भसि ॥ VI (1) 57.11.

तपस्तामरसोष्णांशुः कल्याणकमलाकरः ।
ज्ञानाब्जस्य हरेर्नाभिर्नास्ति तावदयं भवान् ।। V:(ii) 150.38

एतदालोकयसि चेत्स्वयं योगैकसंविदा ।
तत्पश्यस्येव निःशेषं यथा करतलाम्बुजम् ॥ V: (ii) 150. 36.

उत्फुल्लश्वेतनलिनीनिभा नरपतेः सभाः ।
चारुचामरभृङ्गारवितानकशतावृताः ।। V:(ii)145.20

कदम्बोपद्मरागाढ्या मैत्रनीनौत्पलाकुला: ।
दन्तपुष्पफलाकीर्णाः स्मितफेनोपशोभिता: ।। V. 76.9.

प्रवाह का उपमान.
धारा, रय

चतुरङ्गश्चतुर्दिक्कं बलौघः स पराङ्मुखः । (१८)
ययौ प्रावृड्गिरिणादोमहावाह इव द्रुतः ॥ V.(ii) III. 31.

[illegible] ।

([illegible])

आसमुद्रं नदीवाहा इव दूरादुपागताः ।
इदं संपादयामासुर्विस्मयाकुलचेतसः ।। Vidi 12.1.5.

[illegible] : [illegible] : ।

[illegible] : ॥
[illegible] : ।

एतां ततः शुचिस्मेर: श्रिया:
पार्थो विपणमध्ये स्थितः ॥
दत्वा विश्रवसे श्रीमते शिवे
दत्वा हिरण्मयी स्वर्णमही ।
V. 92. 36-37.


GARTA or GARTĀ-- 'A holl

boundary trench (Nos

names it occurs in

GARUTMAD-AṄKA-- Coins or

निर्ह्रादकारि पिंवातिवैहच्छकपकंपारवम् ।
प्रसस्रुपुंवि नीहारा महार्णवरया इव ॥ Vi(ii) 112.29.



Pondasan Upamāna

शुष्यतः कायसरसः प्रगलज्जीवनाम्भसः ।
राजहंसः प्राणनादायुर्निर्वर्ती पलायते ॥ V. 66.24.

पूहरोम नाय सारेवाने
मीरा रपल सरः समस्।
मरपातमरवाते न
मूक मैं नेन साारा॥
V.i.1.16.2

निमलो हृद विरक्तीचे
समजलो हिमरीतले।
मनो निवृत्ति मायातं
स्वरसी शारदीच मे॥
Vi (i) 5.7.



शाम्यामि शीतलाकारः
सुखं तिष्ठामि केवलम्।
प्रसादमनुयातोऽहं
सदा निर्वाणं यथा॥
यो.वा. 5.3.



द्वीपाद्रीन्द्रसुरासुरोरगनरैर्नागाप्सरश्चारणै-
व्याप्तं वारिविलोलितैः सरसिजैरालूनमूलैरिव
एकाम्भोधिसरः स्थितं त्रिभुवनं कालेन निर्मूलितं
कष्टं ते क्व गता महर्द्धिविभवा देवा जगन्नायकाः॥

VI (ii) 139. 67.


अथ कंचित्तदा कालमनुभूय सुषुप्तताम् ।
तदा पद्माकर इव शनैर्बोधोन्मुखो भवम् ।। Vi(ii)146.7.

रसायनपरापूर्णह्रदवत् ह्लादमात्मनि ।


घते करोति वान्यस्य सकलेन्दुरिवामन: ॥ Vi (ii) 102.42

तस्योग्रैर्वह्निवस्येव जलं संशुष्कमिन्धनम् ।
मांसपंकजखण्डाद्वयं हृत्सरः कोशवासिनः ।। V(i) 81.74.

गम्भीरश्च प्रसन्नश्च गिराविव महाह्रदः ।
परानन्दरसाढ्यो रमते स्वात्मनात्मनि ।। V.ii.122.4



बभूवाधापितांगश्रीर्विकासितविलोचन: ।
धारानिकरफुल्लात्मा प्रावृषीवाम्बुजाकर: ॥ Vi(ii)93.2



(६)

बभूवाभासितांगश्रीर्विकासितविलोचनः ।
धारानिकरफुल्लात्मा प्रावृषीवाम्बुजाकरः ॥ V(ii)93.25

सलिलाशनिशस्त्राणामासारैश्चण्डमारुतैः ।
संरासोव विसेतूनि सैन्यानि परिदुद्रुवुः ॥ V:(ii) iii. 30.

कुन्तलव्याप्तमूर्धानां सान्निपातमिवाम्बुजम् ।
भासयन्तं प्रदेशं तं शारीरैर्दीप्तिमण्डलैः ॥ Vi (i) 85.62

Water as standard of comparision.

त्तिः ।

अन्तकः पर्यवस्थाता जीविते महतामपि ।
चलान्यायूंषि शालाग्रलम्बाम्बूनीव देहिनाम् ।। V:(i) 93.85

२ पुराण्यमरदैत्यानां प्रमद्भितोनि शातयत् ।
न रश्मैः क्षणाक्षणायन्ति पयांसीव पयस्वताम् ।। VI (ii) 77. 28

यथा भूतार्थतत्त्वज्ञमाध्यो गगता अपि ।
न मनागपि निष्पन्ति पयांसीव सरोरुहम् ।। Vi (ii) 11.3.

यथावर्तीः पयो भाति धूमो भाति यथा घनः ।

तथा जडात्मकतया तृतीयः सर्गं एतयोः ।। V:(i) 12.16.

यथा वर्तिः पयो भाति धूमो भाति यथा घनः ।
तथा जडात्मकलया तृतीयः सर्ग एतयोः ।। V:(ii) 12.16.

वन्नः शून्यप्रदैः पूर्णैः स्वच्छैरमृतशीतलैः ।
विसृतैरमृताकृत्याशाक्त्राधीवरवारिभिः ॥ प्र॰ (ग) ५५.४.

शाकम्भ > वरवारि

मानवा वातलोलोच्चपत्रप्राप्ताम्बुभङ्गुर-
मानवासु न चास्त्वन्धगर्भशय्यासु सुप्यताम् ।। V.i(ii) 4 3.19

यथोर्मिणोर्मी निहते न काचित्पयसां क्षतिः ।
तथा देहेन निहते देहे नास्ति चितेः क्षतिः ॥ V(ii)99.35

तमस्यवेत भीतानि भूतानि -
।मीलितान्यलम
पर्यासीव विसेतूनि प्रसृतानि
।दिशं प्रति ॥
III 39. 10.

महाकवि कालिदास कृत

के भाई की राजधानी में

होती है जैसीकि वामनपु

धन्यो पादेख वानर चलं
अरविंद देन केलाखो।
मईनो इन्द्र सिंह राजने
इतने दौड़े पहुंच पाया॥

V. (?) 5.12.

अतिभूरितरह्वाणां
पयोवृन्दानि वायवो।
सा निड्र इ तपमत्ताणि
जगत्सन्य न ध हो भवान्

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] से [illegible]

V.8(i) 3.1.

उत्रेषु रवतं तेभ्यो
मूर्तां मे मारस्त्रम।
ईषत्करालवाहाय:
सरिद्भ्यो ईम्बुनच्या हव।।
Vi.i.1.2.

- : : 3

hostile things viz., desire

ब्रह्मणः सर्वशक्तित्वं तत्त्वतो न
विभिद्यते । तरङ्गकणकल्लो-
ल जलौघ इव वारिणः ॥
6.(i).33.11.

1. Nimansako manyamano y
Kakan smehanuprcchati
Anagate napatasi atik
Yadi samprati patasi
Himavanapi calati ---

विरराम मुनेर्वाणि सस्रेवमुधरादिव ।
अथ याते मुहूर्तार्धे राघवे प्रतिबोधिते ॥

VI (i) 29-3.

out of it (Vaiśeṣika Sūtras II. ii. 9 ;
āsya, p.26 line 10). They are produced
be some Force or Power which thus brings
es them off.

प्र: कर्णो पाण्ड पतिका
धा भीमि मे स्तरङ्गः: ।
उ: केनो पाण्ड लाहरी
तरङ्गा नारि नारीतमा ॥
८:१०।११.५०.

ou

nãs

k pe

i.es

कालो गच्छति तत्रैव परां प्रीय-
ति यदा। शून्यशक्तिरविकाशे
परमाकाशगा तदा॥ चेष्टांशो-
न्मुखतो नून (प जटयामेवव
चापलम्। वातस्येव चलनं
पुष्पस्येव सौरभम्॥

6. (i) 34. 15-16.

ही उस से आगे का प्रा

में जब ललनाओं के मुख

भंवरे भी उन्हें सचमुच क

तक भी नहीं--

मुक्ताजालावलीपान्त –
गीतार्णवान्तरभूमिषु ।
प्रचलत्पदगतस्पन्दं लोके
श्रोतृभूमिकास्थिते ॥

Vinoba.

...e is described in the following
...ed, " Let me be many, let me
...ected, and after reflection He
-- whatever there is. Having
...netrated...

धावमानमथो मत्तं चित्तं विमलमाकुलम् ।

बलात्संरोधयामास सेतुर्जलमिव द्रुतम ॥ V. 54 31

se is described in the following

red, " Let me be many

भ्रान्तिमात्रमिदं मोहाज्जगद्राघव दृश्यते ।
जनितप्रत्ययं स्फारं जलं तीव्रातपे यथा ॥ 5.18.28.

संदीभात्साभ्यमुत्सृज्य वहन्ति प्राणवायवः ।
देहे गजप्रविष्टेन पयांसीव सरित्तटे ॥ VI (i) 81.32

इति संचिन्त्य चेतो स्य स्थितं किंचिन्तरान्तरम् ।
स्पन्दसंस्थानसंत्यागमात्रेणावर्तनि ष्व्वव ॥ VI (i) 62. 6.

एकः स्फुरत्यखिलवस्तुषु विश्वरूप
आत्मा सरःसु जलधिष्विव तोयतत्त्वम् ।
संज्ञान्तसंकलनभूरिकलापमेकं
सत्तांशमात्रमखिलं जगदङ्ग विद्धि ॥ V.(i) 120.26.

ऊर्ध्वितां पुनरायाथ पुनरैति निरूर्ध्विताम् ।
यथा जलं तथैवायं तां तामेति क्रियां जनः ।। V.22.35.

त्रैवेदं स्थितं नाम मनमस्तोह नानघ ।
तरङ्गौघगणैरय्यः सिन्धौ स्फुरति नौ रजः ॥

स पपात ततो ध्यानो जलोत्पीड इवाम्बुदात् ।

खादिवानिलनुन्नो व्द इन्दुबिम्बमिव राथे ।। Vi(ii) 93.16.

दृश्यनयामयी चित्तजलकल्लोलहेलया ।
चक्रावर्तौह्यमानेन मयोद्विग्नेन चिन्तितम् ।। V (ii) 93.34,

विधिभिः प्रतिषेधैश्च शाश्वतैरप्यशाश्वतैः ।
यथेष्टं नीयते लोको जलं निम्नोन्नतैरिव ।। Vi (ii) 73.66.

कालेनाकुलचेष्टयान्य इव ते गच्छन्त्यधोर्ध्वं पुन-

र्दैशालेखनखेदितान्यगणितान्यन्यानि चान्यान्यतम्

भूतान्यम्बूनि वहन्ति संसृतिमये तान्यम्बुधौ चंचले ।। VI (ii) 86.59.

आपगा हि पयोमात्रं सङ्गे अर्णवि एव सा ।
यदा तदा तथैवाशु प्राप्य तत्रैव लीयते ।। VI (ii) 85.20.

सर्वत्र संभवाति चिद्‌गनं तदत्र
सद्देदनं कलनमामननं विसारि ।
तच्चाति वाहिकमिहा हुरकुडयमेक
देहं ऽथं कइव तंबद ।कि
(णाद्धि ॥

॥। 40. 64.

सौ संबोध्य शुद्धान्तगतानवोचत् ।
स्मिन्नलंकृतेयं नगरी समग्रा ॥ ११५ ॥

संज्ञो निरीक्षमाणाः सुभगामनुष्याः ।
दृं समेतेति विभावयामि ॥ ११६ ॥

यथैकश्नेष्ठापिण्डात्म बहत्यम्बु तराङ्गिणाम् ।
सबाह्याभ्यन्तराकारमर्थांनर्थमयात्मकम् ।। Vi (ii) 4 3.39

सर्वं त्यजति यस्तस्य सर्वमेवोपतिष्ठते ।

यथैवाम्बु विशात्यग्नौ तथैवायाति वारिधौ ।। V.ii.193.59

सर्वं एवानिशं श्रेयो धावन्ति प्राणिनो बलात् ।
परिभिन्नं पयांसीव तद्विचार्यं समाश्रयेत् ।। V: (i) 97.22

अथास्मिन्कथयत्येवं त्वरातंमपरश्चरः ।

उपच्नवजडोत्स्पोड इव हर्म्यं विवेश ह ॥ Vi (ii) 108.20.

बलादपि हि संजाता न लिम्पन्त्याशयं सितम् ।
लोभमोहादयो दोषाः पयांसीव सरोरुहम् ।। V.(i) 116.2

परां दृष्टिमिमां त्यक्त्वा दग्धराज्ये रमेत कः ।
कस्त्यक्त्वेक्षुरसं प्राज्ञः कटु निम्बपयः पिबेत् ।। V. 34.78.

६ अज्ञानज्वरमुक्तस्य बोधशीतजितात्मनः ।

एतदेव भवेच्चिह्नं यद्भोगाम्बु न रोचते ।। V.(ii) 43.2.

एकं वस्तु जगत्सर्वं चिन्मात्रं वारिवाम्बुधि ।
तदेव स्पन्दते घोर्मिः शुद्धवारिव वीचिभिः ।। VI (i) 101.54.

तपन्ति द्वादशादित्याः प्रज्वलन्ति दिशो दश ।
शीताश्यानाम्बुवच्छैलाः प्रवृत्ता गलितुं बलात् ।।

Vi (ii) 140. 60.

शिखिध्वजदृशामन्ते व्योम्नि पुष्पवपुर्जहौ ।
शान्तावर्तैव वारिश्रीर्मुग्धा स्वं रूपमाययौ ॥ VI (1) 104.31.

महान्ति सुखदु:खानि य: पयांसीव सागर: ।
समं समुपगृह्णाति महाभोक्ता स उच्यते ।। V.(?) 115.26.

उदितं बाह्यतामेति तत्र गच्छति पिण्डताम् ।

स्वयं संवेदनादेव जाड्यादब्धिरिव शैलताम् ।। VI (ii) 49.22.

मत्स्याश्चरन्ति च परी वरवारिणीव

व्योम्नि स्थिराणि नगराणि भुवीव भान्ति ।

शै भूधरा गगनसंश्रयवारिवाह-

मुत्पातवातपरिवृत्तगिरिस्थितं तत् ।। VI (ii) 81.78.

स्थली, रणभूमि, वसुधातल, वसुन्धरा.

अन्त्रान्त्रंतन्त्रीग्रथितशिर: करुरोत्करा ।
आमूलात्सूत्रवल्क्ता कण्टकानामिव स्थली ।। VI (ii) 81.14

२ क्रवारिमयी सायमङ्गुप्तशिलीमुखा
संकुचद्दक्रपद्माभूद्रणभूमिरिवा-
बिजनी ॥

III 39. 8.

बहुत भिन्न है । भक्त के लिए सारा

होकर देवता की स्तुति करता है ।। उ

रहता है । मूर्ती कै रूप मैं वह उसकी

वस्त्र उसे पहनाता है । भोजन करने

परां मन्त्रं प्रयातोऽसि
परमात्मानं निवृत्तिमत् ।
दीर्घायुरन्तरं
वृषेव वसुधातलम् ॥
V

शानवापुताव्कगादला
पद्म पल्लव शालिनी ।
रेरें मनोरक्षीणा
शारदीव वपुष्मता ॥
V. २१. २.

TĪRTHAṂKARAS-- Early sa

They are mentio

(No.16).

UDRAṄGA-- A fiscal term,

(Udgrahas) in Ś

share of the pro

तत एकार्णवापूरो विरिंचनगरान्तरम् ।
रात्रौ पुवपिव ध्वान्तं पूरयामास भूमिमान् ॥ VI (ii) 80.4



Tree as a standard of comparision

अहो नु फलितं पुण्यपादपैर्नः कुलाचले ।
यस्माद्भवानसङ्गो ऽपि वा कृत्यस्मत्समागमम् ।। VI (i) 103. 50.

संसक्तिवशतः सर्वे विवता दुःखराशयः ।
प्रयान्ति शतशाखत्वं श्वभ्रकण्टकवृक्षवत् ।। V 68.10.

अतिशोकपराभूतौ तरस्थतुर्दृढतापनौ ।
तापसंशुष्कसर्वाङ्गौ तावरण्यद्रुमाविव ॥ V. 68.1.

कृपाद्रावाय तत्...

जग्मुर्दिनानि मासाश्च वर्षाण्यथ तयोस्तदा ।
कुमाराावपि संयातौ जरां श्वभ्रदुमाविव ॥ V.66.3.

साधुरौजस्विताभेत्य संतोषेणैव राजते ।
सुपुष्पितवनाकारो वसन्तेनैव पादपः ॥ VI (ii) 47.46.

नः

पूर्वैं संसृतिवैरस्यमन्तरेवोदितात्मनः ।
जायते जीर्णजाड्यस्य पाकादिव शरत्तरोः ।। VI (ii) 47. 27.

अन्तर्बहिस्त्वमहमित्यपि चैवमादि
सर्वात्मकं तपति चिन्मय एकमेव ।
शाखाशिखाविटपपत्रफलैकदेहः
संकल्पवृक्ष इव बोधघनमात्रसारः ॥ V:(I.) ९९. ५१.

क्रमात्समाधानतरोराजोवफलशालिनीम् ।
सत्ताकुसुमां ब्रूहि सतां विश्रान्तिदां मुने ।। V(u) 55.1.

त्नौ प्यफलौ प्येकौ सपूर्णौं प्यत्नसंगति:
या प्यत्र वने शाखौ घुणाद्घुण्णा इव द्रुम: ॥ Vi (i) 87.13

स शाखाफलपुष्पं स्वमजहद्बीजकोटरे ।
यथा तरुः स्थितस्तद्वद्विकासि चिदणोर्जगत् ॥

III. 81. 96.

...nana, avidya or ...

...ich is capable of projecting thi...

...rapanca. Bhartrhari calls this

...nd avidya. And like all other

anirukta. This is set forth by H...

in his Vrtti on I.4. Says he : '...

इहो मगवता हिमवत

पुष्पा होइ दक्षी तातरविपात।

इह धीमाना मृतवेतन

धारेहिना: सद्धर्मा भवम्॥

Vi, i, 16. 10.

प्रणताः शरणागताः स्फुरन्तीह
ते मोदयन्ति पादनखाः ।
ये पद्मालोला चितालम्बा या
प्रपराम्भू च संनिदेः ॥

Vi (i) 6.22

पट पदसोगने न ठना

पट्ठो न विवाद रखनो।

मिलणोहे नी शरीराथे

[illegible] चूनरोरिव॥

Viy (8.2.

पचा प्रीआ दूद्दूस्ये

र्स्होमे क्षा हो तिकालाठ।

त वेवेदं, ल हेक्त ल्पा त

स्हेवेयम ह दु (ति) लम।

७.७१, ८८

. : :

'ā/ljapate' or 'ā

[illegible]

[illegible]

[illegible]

[illegible] ॥

6.(1) 30.61.

ने अहिंसा के सिद्धान्त पर बल दिया ।
किया । उनका भारत के रंगमंच पर प्रकट
न्यताओं पर गहरा प्रहार करना भारत के
थी । इनके पीछे अनेक जातियों के विद्रोह
और जैन धर्म का ही प्रभाव है कि कुलीन
का परित्याग कर दिया। आर्यों में गिनने

[illegible]

[illegible]

[illegible]

[illegible]

१. ४. ३७.

ey do not s
tion with Alexander. Their
from Sutlej to Bharatpur an
ere modern Johiyas are their

अकृत्रिमसुखं प्रेम वियोगे शतशाखताम् ।
प्रयाति पल्वलतटे छिन्नमूल इव द्रुमः ॥ V.61.26.

from Sutlej to Bharatpur and S.part

यस्तत्रार्थं परिज्ञाय जनैर्दूरे निराकृत: ।

यथा राशिरनर्थस्य यथा ग्रामे विषद्रुम: ।। V. 47.61.

from Sutlej to Bharatpur and S.part

तत्र ते करुणाक्रन्दाः ससुहृद्बान्धवाः ।

प्रदग्धाः पर्णविटपा वृक्षा इव वनानिलैः ॥ (V. 30.11)

अवतीर्णानां च तेषामवतरणप्रकारमेवाविर्भो-
देति तत्त्वज्ञानं दृढतामेति तदनु शतसहस्रस्कन्धो
विचित्रशुभाशुभफलभरफलितो भूरिशाखः स्फारतामेति
संसारद्रुमः ॥ IV 39.50.

१

आत्मरत्नावलीकैकदीपिका परमात्मिका ।

यथायुक्तिलतोदेति स वन्द्यः सुजनद्रुमः ॥ V. 4. 6.

सहस्राङ्कुरशाखात्मफलपल्लवशालिनः ।
अस्य संसारवृक्षस्य मनो मूलमहाङ्कुरः ॥ V. 9. 55.

अस्य संसारवृक्षस्य मूलं दोषाङ्कुरास्पदम् ।
भव्य घोरेण धैर्येण प्रोद्धरोद्धुरया धिया ॥ V 13. 34.

कदाचित्स द्विजश्रेष्ठस्त्वहव्यापारनिष्ठया ।
पुष्पापान्तर्व्यवहृतिर्बीजतायामिव द्रुमः ।। VI (i) 62 .।।

बृहत्स्तनस्फुरत्प्रौढसच्चावृततिकोटिगम् ।
अहंकारमहावृन्तं समालोकसमुज्ज्वलम् ।। V. (?) 13.9

नृपाः पौरा विटपिनः पुष्पं वातघुता इव ।
पूजयित्वा मुनिश्रेष्ठानुदतिष्ठन्स्वविष्टरात् ।। VI (i) c65. 16.

त्रिजगत्रास

त्रिजगद्रासससंतृप्तः प्रगायन्निव घर्घरैः ।

स्वैर्नृत्यन्निव चोग्रादिकटकैर्वोचिदोर्द्रुमैः ।। VI (ii) 78.22

आशाख्याश्चित्तवृक्षस्य शाखा: स्थगितदिक्तटा: ।
तासु छिन्नास्वल्पत्वं याति चित्तमहाद्रुम: ।। V.21.22

तथा तत्रैव तं भूपमपश्यद्वनभूमिगा ।
निर्विकल्पसमाधिस्थं समुत्कीर्णमिव द्रुमम् ।। VI (i) 103. 6.

शरीरे निमिशिचराह्ढो गिरौ तरुरिव स्वके ।
अहंभावो महाभाग वद मे त्यज्यते कथम् ॥ Vi(1)74.32

विप्रोत्तिष्ठ पयोमध्यादगृहाणाभिमतं वरम् ।
अमोघस्वनफणोपेतो जातस्ते नियमद्रुमः ।। V. 44. 11

अहंत्ववटधानान्तः स्थितदेहवृहद्द्रुमः ।

संसारशाखानिवहं यत्र तत्र तनोत्ययम् ।। V. (नि) 17.12

परिवेल्लितमन्योन्यं फलक्रान्तं द्रुमं यथा ।
द्रुतहेमरसापूरनिर्भरा भोगभासुरैः ।। V.(i) 85. 71.

आजीवमुच्चदुत्सेधं विवेकिजनकानने ।
पत्रपुष्पफलोपेतं समाधानतरुं शृणु ॥ V (ii) 44. 2

फलिते शीतलच्छाये सत्संगसफलद्रुमे ।
स्रवत्यानन्दसुरसे समाधिसरलद्रुमे ।। IV. 35. 12.

गणाङ्गनानामनिशं मत्तानां चरणैर्हता: ।
अशोका इव राजन्ते यत्राशोका विलासिन: ॥ V. 58. 6.

बोधार्कपीतरसया स्पन्दन् षड्वर्गसितया ।
यन्त्रस्पन्दोपमस्तिष्ठ वल्लयेव शिशिरे द्रुमः ।। V.(ii)1.20.

;

वासनारससंसिक्तादहंबीजकणादयम् ।

क्रमादौ व्योमविपिने जायते त्रिजगद्द्रुमः ।। V. (6)/115. 3.

संनिवेशनिवासात्मा सर्वार्थादिः परे पदे ।
विद्यते नान्यदन्यत्वान्नभसीव महाद्रुमः ।। V. 6.194.34

विलोनानान्तरांश्चैः स्पर्शानुज्झितदर्शनात् ।
रसान्विटपकोशस्थान्मार्गशीर्ष इव द्रुमः ॥ V 54. 36 37.

अन्यैः पार्श्वगतैर्दीनैः प्रवदश्रुमुखैर्जनैः ।
श्रितं गद्गदवश्यायैः शुष्कपर्णैरिव द्रुमम् ॥ V. 44.28

नानयोर्विद्यते भेदस्तरुपादपयोरिव ।

यानीमानि जगन्तीह नान्यतानि चिदाकृतेः ॥ VI (i) 47.21.

अन्तर्जलविधौ तस्मिन्विस्मृतध्यानमन्त्रधीः ।
पर्यस्तसंवित्प्रसरः सो पश्यज्जलमध्यतः ।। V. 44. 20.
मृतमात्मानमात्मीये सदने शोच्यतां गतम् ।

इत्यसौ ज्ञानविटपी लतापल्लवपुष्पवान् ।
भविष्यज्ज्ञानफलदो दिनानुदिनमुत्तमः ।। V.(i) 44.25.

अस्या: संसारसल्लक्या वासनोत्सेधकारिणी ।

कदल्या वनजालिन्या रसस्येव माधवो ।। V.i (ii) 25-5.

मन्ये भवति मे भर्ता शुष्कवृक्षसमस्थितिः ।
तथापि चित्त कौत्कण्ठा भवतोत्कण्ठयान्वितम् ।। Vi.i.85.39

न । चि चलेनन चेन्नाटि
नहुंके खदिरे यथा।

५०।३१.७.

शुष्के तृष्णातटे शान्ते मन्दे हृदयकानने ।
गोणौ स्वदाकदम्बेषु मिथ्याज्ञानघने गते ॥ IV. 35. 58.

देहस्तावदयं ब्रह्मन्कर्मवृन्दा: समुत्थित: ।

रूढ: संसारविपिने विचित्राङ्गलतान्वित: ।। V.(ii) 2.

अहंकारदाये देह: किन्नावश्यं विनश्यति
पूते ककचसंलूने सुमहानिव पादप: ।।

V.16.4.

दि. पृ. रा

वैमानिक इवापुण्यश्छिन्नमूल इव द्रुमः ।
वात्यक्त इव पाषाणः स पपात ततो वनी ॥ V.(ii)93.

नष्टात्मपरिस्थितयो भोगवह्निषु प्रज्वलन्त्यलम् ।
देवा दिवि दवेनाद्रौ दह्यमाना द्रुमा इव ॥ V:(ii) 17.2

तालीतमालदलताण्डवमण्डिताशं

व्याकोशपद्मवनवन्यविकासिवृन्दम् । Vi(ii) 151.1

मैं। वि [illegible]
[illegible] लिखदो ज्यादा।
बापु ३१. ७.


more food and other nece
procured only if more la
existing land is cultiva
waste lands were availa

पर्वी एव स्थिरो भावा देहदार्घमादयः ।

दिप्रमांशुष्कविकलाशरावविशरारवः ॥ V.(गं) 26.9.

इसु.

द्रष्टृदृश्यै न यैवैकमप्यविष्यच्चिदात्मकै ।
तद्दृश्यात्क्वात्मपन्नः स्यान्ना दृष्टेन्दुमिवोपन्नः ॥ Vc(ii) 38.9



हिम & हिमकण
मिहिका
तुहिन & तुहिनाणु तुषार, सीकर

यथातपे हिमकणः शरद्व्योम्नि सितोऽम्बुदः।
दृश्यमानोऽप्यदृश्यत्वमित्येवं योगिदेहकः॥

III. 57. 23.

tudies,

23-

Da

The Director,
Oriental Rese
Mysore.

Sir,

Thank
dated 25.9.19
manuscripts N
Padamanjari(K

अगनि प्रदक्षिणां गतां नूतं
(ति) हिरनाकस्यप से।
दैत्यराज [illegible]
नरसिंह [illegible] ॥

प्राणि का रूप (हिला
धान दे का बनो करतो।
नानदेव गानलकार हु
[illegible]

U. 11. 10. 36

प्रार्थना समाज के मन्दिर पर

[illegible]

[illegible]

[illegible] ॥

[illegible]

यथा नन्नगिरिं प्राप्य हिमलेशो विलीयते ।
शुद्धमासाद्य चित्तत्वमविद्या लीयते तथा ॥ VI (i) 58.8.

विद्वे शान्ते शाम्यतीयं संसारमृगतृष्णिका ।
जरामुपगते मेघे मिहिका तन्मयो यथा ।। Vi (i) 69.55

ने वरिला वरेनुं वे प
तुकारे तु मने वाता ।
पि. वी । ३१.१०.

ured by rivers and rainfall. There

mes to play. People arrange

They excavate tanks, lakes, pools

on. As far as history takes us back,

विवेकिषु विरक्तेषु संसारोत्तरणार्थिषु ।
जन: शीतलतापैति हिमकारगृहेष्विव ॥ VI. (ii) 47.4

country

p.t.o.

तैनासुरपुरन्ध्रीणां नित्यं मण्डनमण्डनै ।
मुखपद्मे स्थितं बाष्पमलिनीनां हिमं यथा ।। V. 31.25.

एकरूपस्थिरं चक्रं स्वच्छं संतापवर्जितम् ।
नेह संप्राप्यते किंचिदग्नौ हिमकणो यथा ।। V

मायेयमतिदुष्पारा सांसारी गाढतां गता ।
शरदा मिहिकेवाशु बोधेनायाति तानवम् ।। ६.२.११२.*

इदं प्राप्तमिदं नेति जाड्याद्वा धनमोहदाः ।
आधयः संप्रवर्तन्ते वर्षासु मिहिका इव ॥ Vi(i) 81.16

पूरितोत्करपुष्पाणि तरङ्गौघटानि च ।
प्राप्तान्यम्बुवनानीव लहरीमंजरीणि स्वम् ॥ V [illegible] 13.

श्रींपत्यपि पतन्त्याशु शातना: कातरादय: ।
गुणावत्युग्रपत्रे पि तुहिनानीव पङ्कजे ।। Vi (Ti) 6.4

Hermit as an उपमान.

तमथासौ तथा बुद्धिफलपल्लवशालिनम् ।

आनन्दमन्थरमना: पुष्परूपावलीपमम् ।। IV.50.1.

पतन्पादपद्माभ्यामप्राप्य करिणः शिरः ।
पातौ व्यौ फलं पक्वं वाताहतमिवाकुलः ।। Vi... P8. ...

देहान्यनानि सर्वाणि कालेन कमलेक्षण ।

साधो वृक्षात्फलानीव पाकेन विगलन्त्यधः ।। VI (i) 101.13.

।स्निग्धगम्भीरवचनः
स्मितपूर्वाभिभाषकः।
परस्वेष्वनभिध्यालुः
प्रोक्तो नित्यं जनाश्रयः॥

ईषत्स्पन्दादधो याति भृगुप्रा-
न्तात्तरोः फलम् । यथा तथैव
संवित्तेरधः पातो महानिव ॥ ।
6.(i) 31.28

भाषा में गाड् शब्द का अर्थ आदि में घृत और

की देवताओं के प्रति प्रार्थना भी जो भावना थी उसमें ~~भावना में~~ भी मित्रता का सा

ने देवी देवताओं पर विश्वास था कि वे उनकी

ारणा थी 'ददामि उतददासि" क्योंकि मैं तुम्हें

ुझे दोगे ।

होम से बहुत भिन्न है । ~~इसके~~ भक्त के लिए सारा संसार

सक्रिय होकर देवताकी स्तुति करता है । उससे

इत्यतीतविलासानामुदीरणम्
लोकैः पृथक् इव सन् ।
यथा तादृश्या विरोधोऽयं
दाडिमानीव भासन्तेवा ॥

III. 45. 25.

यत्नेनापि पुनर्बद्धं केन वृन्तच्युतं फलम् ।
देहस्तु देहधर्मेण जीवन्मुक्तिमतामपि ॥ VI (ii) 125. 32

द्विगुणा नभसस्तस्माद्दृढा चक्रस्य पुष्टता ।
दशदिक्कं विसरतो बिल्वत्वक्सदृशस्थितेः ॥ VI (ii) 127.17.

ऊर्ध्वाधरस्थपरिवृत्तपदार्थजात-

यत्नेनापि पुनर्बद्धं केन वृन्तच्युतं फलम् ।

देहस्तु देहधर्मेण जीवन्मुक्तिमतामपि ।। V: (i:) 125. 32

ऊर्ध्वाधरस्थपरिवृत्तपदार्थजात-

मन्तःकणैः क्षणक्षणायितशैलमज्जम् ।

ब्रह्माण्डकोटरमभूद्विधुरं कुबाल-

लोलाविलोलमिव बिल्वफलं विशुद्धम् ॥ VI (ii) 77. 49.

कर्षिवदुत्तमफल्गिनो फल्गिनोव फलान्वता ।

धरा तव फलापूर्णैः पूर्णं धारयति प्रजाः ।। V. 61. 33.

धामन्वतामवापासौ विप्र: संततचिन्तिताम् ।
सातत्येन रस: पीत: फलतामेति पादपे ।। VL (1) 63.15.

अवस्तुत्वादविद्याया वस्तुशक्तिरपि क्वचित् ।
म्रियते दृश्यते ह्यङ्ग वसन्ते शारदं फलम् ।। Vi.i, श्लो. ५८.

मित्रबान्धववृन्दानि जन्तोर्जन्मनि जन्म
ऋनावृतावतीतानि फलानीव महातरौ
V. 19. 38

इलाज

नप्रम्

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] | 37-38

V.92

-

religious matters; a th
universe and everything
the Divine One". (No.55
DŪTA-- An occasional substi
of an ordinary message-
DŪTAKA

रागेणे — कर्दुः कोलां
विनश्शा दुवमायते।
दुवालोन्दु विलालेन
तेमसलामिव मेलाकुला ॥
V. 9. II. 48.

istts. of Raipur, Sambhalpur (Oriss

. Acc. to Hiralal it included

pt.,1933) (No.1).

rom which Hanumat took a leap throu

iven as the name of a mountain at a

e only other place where its mention


Buddhist insc. (

फलाद्वैः आत्मनः परस्मात्
सर्वं वेदादिसंशयः ।
नूनं विमूलतां यातो
हृद्ग्रन्थे दृष्टा नमः ॥


Vino 5.10.

भोगानुभ्यासानि धानेरणे
ध्यैवोप शमें गात्रः ।
तद्वैव मस्तसरानि –
प्रान्ह्यं स्वान्तसपर्दिवा ॥
V(i) 6. 3.

धनानि नाभिवाञ्छ्यन्ते तमांसीव विवेकिना ।
त्यज्यन्ते विद्यमानानि मंशुष्कामेध्यपर्णवत् ।। VL (ii) 48.3.



भिन्नांजनतमः श्यामा यामिनोवाकृतिं गता ।
नमः श्रीदेहयुक्तेव साकारैवाम्बरद्युतिः ।। VI (ii) 81.9.



गङ्गा तरङ्गिका येषां तादृशैः सरितां गणैः ।
बर्ह्रिव नभोभोमैः पूर्यमाणाखिलार्णवम् ।। VI (ii) 77. 9.

स स्वातन्त्र्यं चक्रे हस्तिपः कानने स्थितः ।

सर्वदिक्कं विधिर्भूम्नो समुद्रवल्यं यथा ।। V(i) PP. 23.

कढिश.


तरवः हतहृतं मिलितेन

तदेकोऽस्मि नुहुँ हृतम्।

तादृशेन पदधे मे दत्तं

नानारूपेण कदेमे ॥

V; (i) 6. 31.



कर्दमादि यथा हेम्ना श्लिष्टमिति पृथक्कृतम् ।
नात्मा परिणतिं याति जडो देहस्तथात्मना ॥ V. 5.32

तन्तु

अचितत्वं गते चित्ते क्षीयते वासनाभ्रमः।
हरिमुक्ता समानेवारि दुल्ने तन्ता विधानं ॥

VII (i) 4-6

not. The continuity of

of an ideal series of mo

together the moments -


and future and this con

various lengths.

It is interesting

and does not share the

Desert as a standard of comparison.



अज्ञानविस्तीर्णमरौ विलीनं


शुभाशुभस्यन्दमयैस्तरङ्गैः ।

सवासनानामपरोक्षवारि

परिस्फुरत्यैतदनन्तरूपम् ।

V. 19.51.


कुतोऽप्यचेष्टितेष्वेव संप्राप्तेषु विधेर्वशात् ।
भोगेष्वरतिमायाति पान्थो मरुमहीष्विव ॥ V.(ii) 45.25



[illegible]

अहं पुष्करपन्दारकुसुदोत्करमालिता ।
पृशं दाहमवाप्नोमि कण्टकैष्विव दीलिता ॥ VI (ii) 64. 62.

पातनैकान्तददाणि दोषाशीविषवन्ति च ।
हृदाकण्टककल्पाणि इवभ्रागाणीन्द्रियाणि च ॥ [illegible] 6.55.



Mukula

Mañjarī as an Upamāna.

सर्वस्याह्लादनी शान्ता मैत्री परमपावनी ।
अभ्युदेति हृदो हृद्या सुतरोरिव मञ्जरी ।। V. 83.18.

विश्वलोकेर मोवला ह –
प्रोत्फुल्ल नफनालिनि।
पुरन्दिर् वोरो गक्मी –
तरुमञ्जरितां गाने॥

V. 14. 1. 5

rting that we have in Manusmriti

38

ed up with the Vedānta.

the Purāṇas. According to the

the Purāṇas as a whole deal with

.verse, recreation of the universe

menets, genealogies of gods and

ages in l...

गीताम्बुज मनोनाहै
स्वर्णव काविन हिमालये ।
परमन्त इव मज्जन्ति
स्फुरन्ति अंगुष्ठलवनदम् ।
V. १०. 22

- : :

grandfather, and

in respect of th

PĀDA-PADMOPAJĪVIN-- 'Su

are the feet,' a

feudatory to his

PĀDA-PINDOPAJIVIN-- 'Su

साधु राम त्वया प्रोक्तं जाता ते षोडशभागिनी ।
मतिरुत्तमनिष्यन्दा नन्दनस्यैव मंजरी ॥ IV.21.4.

तया परमया दृष्टया कलंकान्तरस्थया ।
म जरी गन्धशक्त्येव पदार्थेषु विराजते ।। V.13.62.

अवस्त्विदमिदं वस्तु यस्येति लुलितं मनः ।

तस्मिन्नोदेति समता शाखोट इव म जरी ।। V 13. 24.

अपश्यत्स्वात्मनि स्वप्ने सुरस्त्रीत्वमनिन्दितम् ।

वृद्धा कोशरसोल्लासे पंजरीत्वमिवोदितम् ।। VI (i) 62.15.

या या जनस्य विपत्ते ...

मनसा मानसोभार्या मन्दरोत्तमसुन्दरी ।
ततो वृद्धिं प्रयातास्मि वसन्त इव मंजरी ॥ VI (ii) 64. 48.

या या जनस्य विपदो भावाभावदशाश्च याः ।
तृष्णाकरंजवल्ल्यास्ता मंजर्यः कटुकोमलाः ॥ IV.27.30

अशोक इव प जर्यः पुष्करावर्तविद्युतः ।
न स्फुरन्ति जगत्कोशे तनुं त्यजसि किं मुधा ॥ V. 39.30.


यश: कुसुमगुच्छाढ्यो गुणपल्लवलासवान् ।
वैराग्यरसविस्तारो प्रज्ञापंजरिताकृति: ।। Vi (ii) 44.26.

कासश्वासरणाद्भुङ्गा कलेवरजरद्वपे ।
विकसत्यपलीपोता जरामरणाय जरो ॥ V. ४३.९.

अविद्यैव मनन्तेयं नानाप्रसवशालिनी ।
जडा दृश्या रसमयी मोहमायवमंजरी ॥ Vi(ii) 160.13.

कायजीर्णनिरोरस्माद्वान्यवाक्रन्दषट्पदा ।
जराकुसुमितोदेति पुनर्मरणमञ्जरी ॥ V. 66. 15.

क्रीडन्तं त्यक्तवसनं देशे पुरुषवर्जिते ।
का वराम्भोजमुकुलसंकाशैः स्तनमण्डलैः ॥ V.iii.85.90.



... उपमान.

बिन्दु

बुद्बुद, अम्बुविप्रुष:

III (a).

निर्यादफलोझ्याला वते
परम सामील केन्द्रवा।
पुनःश्चैचालिला राम
मूतसिनते विस्तरनय ५
(मा). १५.२.८.

निर्मरी दम्भलोभमोह ते
कपसामित निंदका।
ज्ञानदेवा विला राम
सूतांनी तिरस्करता ५
ता. १५.२.८

the intellect and differe

---

1. Anyaistu bhavairanyesa
Sanairidam idam ksipre

सिकरानलि इरो –
[illegible] पचसो पपाना
[illegible] राम
[illegible] ई [illegible]
११-१५.२४

is connected with the

every heart felt relei

spirt in the form of N—

The philosophi

अर्घो भाता भवत्याय च्छोके स्यावसंरोहि कः ।
यं हत्पुदेति स्फुरति पुरतु दोष इवार्णवे ॥

अ

उ

VI (i) 28 - 57.

coming together, that
tion. When, however, they enter into
s another and form compounded wholes i.e.
or biological) then only the special
they can appear only when

निपदश्रुषी स्फुरन्नपेता
देहश्रुकुद पञ्चत्यय: । इतप्रया-
णा इतप्रयाणा एतास्वास्था
न धीमत: ॥
6.(1) 33.5 ।

2. Sadasadvapi vastu syat

Tena bhuta bhavisyanta

अत उक्तं मया राम यदि शुद्धे हि चेतसि।

उपदेशः प्रसरति तैलबिन्दुरिवाम्भसि ।। V.(ii) 16.4.

2. Sadasadvapi vastu syat

Tena bhuta bhavisyanta

अत उक्तं मया राम यदि शुद्धे हि चेतसि।
उपदेशः प्रसरति तैलबिन्दुरिवाम्भसि ॥ V.(6) 16. 4.


विनाशायैव जायन्ते जडा देहेष्वबुद्धयः ।
अनारतोदयाः पापा बुद्बुदा जलधेरिव ॥ V.14.16.

यान्ति चेतसि विश्रान्ति विमला देशिकोक्तयः ।
यथा सितांशुके शुद्धे बिन्दवः कुङ्कुमाम्भसः ।। VI (i) 10 | . ॥

कल्लोलैरुह्यमानानां नृणां संसारसागरे ।
अज्ञाता दिवसा यान्ति तृणानामिव बिन्दवः ।। Vr(ci)97.23


साद्रिधूर्विनदीशानां वनधूग्रामपूर्दिशाम् ।
कप्यं पयोन्मुवाङ्गानां बुदुदानाभिवाणवि ।। Vi (ii) 145.38 G.

आत्मीयेष्वर्थजातेषु मिथ्यात्मसु सुतादिषु ।
बुद्बुदेष्विव तोयानां न स्नेहस्तत्त्वदर्शिनाम् ॥ V: (ii) 102.16.




मन्दोत्साहाः समुद्भूताः सम्यक्संघातवर्जिताः ।
न तदाज्ञाः पदं प्रापुर्मनस्विनो वा मुमुक्षवः ॥ V. 46.26

विकारादि तदैवेति पुंवौकिरनर्थिका ।
ततां समुपयात्याशु जलबिन्दुरिवाम्भसि ॥ VI (i) 46. 26-27.



नारक.



प्रययुः क्वापि दीपौघा दिवसेनेव तारकाः।
आययुर्बलिमालोला नैशाभूत परम्पराः॥

III. 46. 17.

अयं प्रबुदो य

दधामहं लोचि

यथा पुरा का

पटस्य खण्डइ

इत्याकल्प्येत्य

अयँ स्वयं पर्यं

इति निर्णीय तावुच्चैरुत्सृतौ तारकोपमौ ।
सपक्षपुटोड्डीनौ व्योम यन्त्रोपलाविव ॥ V.(ii) ९५.5.

तारकासीकरासारो नभोनन्तनिखातवान् ।
भावाभावमहावर्तो नानागिरितरङ्गकः ।। Vi(ii) 15.6.

वायु: अनिल, पवन, वात, वातल etc.

Wind as an Upamána.




निमेषार्धविभागेन कालेन कलनां प्रभुः ।
जहौ चित्तश्चैत्यदशां स्पन्दशक्तिमिवानिलः ॥ VI. 87.12

पुर्यष्टकोदयादेव स्वयमात्मानुभूयते ।
सर्वदा सर्वसंस्थः स्वे घनास्पन्दादिवानिलः ॥ V.73.22

मनांसि दीपयत्येष पल्लवानीव मारुत: ।
वाहयत्यदापद्दिक स्वामश्वानीमिव सारथि: ।। V. 35. 8.

विस्तीर्णां मिंघटापद्टपाटपद्टनपाटवैः
दर्शयन्तो जलाम्भोदनिष्क्रान्ति मारुता इव ॥ VI (ii) 122.13.

सौषिर्यसंभवात्प्राणपवनस्पन्दवर्जितः ।
प्रोन्मत्स्पर्शपूरेण शिलापूरेण तर्जितः ।। V(ii) 145-53.



न विवेचन प्रेरित है

मई. इस बार [illegible] है।

[illegible]

दोनों मन्दा मिला इस [illegible]

V.93.12

in earlier times one of the
ty used by Kaniṣka, Huviṣka
Gupta and subsequent period
s a technical official title,
derable rank and power, but not
t to paramount

सर्व संस्कार अनित्य -

शांत समाहित हे सुने ।

सद्गुरु [illegible] सुनते [illegible]

स माइन सम कमो ॥

V. 73. 83.

the Pr

MAHĀRĀJA-- Li

of par

va. Bu

habitu

tive no

only to

सङ्कल्पानिलनिर्धूतं भ्रान्तं
पर्णतृणांशवत् । भूताकारो
चिदात्मानं सर्वत्रैव विलोकय ॥
6.(i) 33-39.

पुराणों में भी सुनाई जाती है
अन्य अवसरों पर पुराणकार की
भावों के आवेश में सीधा सादा पुराण
लगने लगती है, उत्प्रेक्षा मचल उठती
की कविता ।
स्थल कहां हैं और कितने हैं यह
। सम्भवत: पुराणों का

संकल्पवातवलितं जन्म-
जालकदम्बकम्। असङ्क-
~~ल्पवातबलित~~ ल्पानिल स्पर्शा-
~~द्विभाम्याति~~ परे पदे।।
6.(1) 33.43.

रण किया करते थे । ऐसा विश
से देवता प्रसन्न हो जाते हैं ।
भी प्रचलित थी । घृत अथवा अन
मीन भाषा में `गाड` इस परमा
वन सामग्री ही थी । [1] देवताओं
ा मित्रता का सा पुट मिला हुआ
विश्वास था कि वे उनकी सहायता

एकाँसदौ दयौः सिद्धिबौँधवैतृष्ण्यदोपयोः ।
पतिवात्याभुतौ व्योम्नि दग्धो ज्ञानाग्निनाखिलः ॥

U. (ii) 45.56.

तथेत्युक्तं मया सार्धं गन्तुमारब्धमम्बरे ।
वात्यया सौरभेणेव शून्ये शून्येन शून्यया ।। VI (ii) 67. 2.

पादपः पवनेनैव भूकम्पेनेव पर्वतः ।

भस्त्रा भस्त्राभरेणायं देहश्चित्तेन चाल्यते ।। V ..., 73.3A.

संकल्पेन यदा याति त्वसंकल्पेन गच्छति ।
पवनेन महाबाहो ज्वालाजालमिवानले ।। VI (i) 100.26.

यदा स्वभावान्निष्क्रम्य करोत्यादानमीश्वरः ।

जीवो गृहीत्वा संयाति पुष्पाद्गन्धमिवानिलः ।। VL(i)55.24

कदम्बनीपजम्बीरपत्रस्तबकसद्मसु ।
सुवविश्रमणं स्त्रीभिः नाकं पद्मेष्विवालिनः ।।

Vi (ii) 145.69.

Bīja or Bījakaṇikā used as a standard of comparision.

एतामनुसरन्मायां चित्तसत्तामपावनीम् ।

संसारबीजकणिकां जीवबन्धनवागुराम् ।। V. 15. 1.

वागुरा also

असक्तानां ततो भूयोऽत्य पुना राम न जायते ।
दौत्रेष्वपि चिरं तिष्ठन्बीजं दग्धमिवाग्निना ॥ IV. 48.4.

सम्यग्बोधवतामेषा वासनैव न वासना ।
ज्ञानाग्निदग्धा दग्धस्य कैव बीजस्य बीजता ॥ V. 84.26

वासना compared to बीज. ज्ञान with अग्नि.

समाधिबीजं संसारनिर्वेदः पतति स्वयम् ।
चिरमूर्मौ विविक्तायां विवेकिजनकानने ।। Vi (ii) 4 4.5.

समाधिबीजं संसारनिर्वेदः पतति स्वयम् ।
चित्तभूमौ विविक्तायां विवेकिजनकानने ।। Vi (प) 4 4. 5.

१ इन्तत्मैं नधना (मम-
२ प्रतिश्रुमसाडु·रम् ।
संस्मृतेव्रततेवीजं
शारीरं त्रिविधं सपव ॥
५।६
प. ९१.४.

that people fr

Panjab, and th

exterminated.

VAIDILA -- A word requi

VĀKĀṬAKA -- Dr.Bühler s

are not mentio

the

[illegible]
[illegible]
[illegible]
[illegible]

V. ૧૧. ૫૬.

the use of √yuj, wi
commission', in Junagadh R.Ins. No
'tan-niyukta' in No.39, line 76,
' in No.1.
istrict, province, etc.,' is a
śa 'A region, country, provime,
on), 'maṇḍala' (A circle, district
, etc.), and '..

त्रियते शोणितसंसारऊलना
कल्पनात्मिका । भ्रूणबीजो-
पमा सता जीवस्य अति-
नामिका ॥
6.(i) 34.8.

न
वापक्

-डा

विरजं निगताचारं मनो
हि चिन्मतं मुक्तं ।
निष्कलोऽमयं लब्धाऽगला-
दितरन्नीजवतं ॥

6 (i) 32. 27.

nt. According to Vātsyāyana,' the
n is manifested directly by an actual

---

iriti yasmadekabhavenyatarabhavadu-

a, II. 42. p.303. The same edition.

अहंभावनमेवोच्चैर्बीजं दुःखाख्यशाल्मलेः ।
यथेदं तददादीति शाखाप्रसरकारणम् ॥ V. (ii) 116 8.

अनारतविपर्यासकारिमारुतनिवृत्तम् ।
बीजराशिरिवाजस्रं पूर्यमाणं पुनः पुनः ॥ VI (ii) 77.41.

नो चेत्पतति चित्तौ कल्पनाबीजकं ततः ।
चित्ताङ्कुरा न जायन्ते सुखदुःखलवद्रुमाः ॥ VI (i) 49.35.

जरामरणजन्मादि करंजखदिरावलैः ।
बीजपिण्डा सदैवान्तर्दहतां शमवह्निना ।। V.(ii) 36-39

तद्दग्धबीजवद्भूयो नाङ्कुरं प्रविमुंचति ।
देहेन्द्रियादिना कर्म करणाधेन कल्प्यते ।। Vi.ii.120.21.

प्रतिकन्द: 'शरीराणां बोजं त्रैलोक्यवोरुधाम् ।
सर्गार्गलप्रदो मुक्तै: संसारासारवारिद: ।। VI (ii) 73.39.

भृष्टबीजोपमा भूयो जन्माङ्कुरविवर्जिता: ।

हृदि जीवद्विमुक्तानां शुद्धा भवति वासना ॥ V. 42. 14.

अभ्यासाद्दृढेन सत्यसंबोधवह्निना ।
निर्दग्धं वासनाबीजं न भूयः परिरोहति ।। VI(1)57.10.

समुद्र

स्फुरन्ती प्रज्वलद्रूपा संध्या जलधरारुणा ।
दधाना गगनाम्भोधौ वाडवज्वलनश्रियम् ॥ Vi (ii) 134.11.

अथैवमस्त्विति प्रोच्य पावकः सहसागमत् ।
दाणादीर्वितया यातुं समुद्र इव सत्वरः ॥ Vi (ii) 126.16.

लुठन्तमिव हैमन्त लोडयन्तं जनास्पदम् ।
वीचिविदारीभचपलं परिचितमहार्णवम् ॥ VI(ii) 78.13.

आश्रयैतैकविश्रान्त्यै श्रान्तः संसारवर्त्मना ।

यस्मादत्यन्तविषमः संसारोरगसागरः ।। V. (ii) 98.16.

प्रेम [illegible]

[illegible]

[illegible]

यथा [illegible]

[illegible]

प्रमु.उ.। गोरेवालाना

उपनिरीक्षक बालाना।

पत्र [illegible] विचारार्थ

[illegible] मे भेजना।।

८.११.५१.

or sanctified teachers of the Jains
es 'Ādi-kartṛ-s', Lit. 'originators.

plained by 'uddhara' and 'udgrantha'
a-koṣa, and thus seems to mean 'the
e collected usually for the king; th
usually 106th of the produce'.(No.21
quiring explanation.(No.55).

विवेकवानुदारात्मा विजितेन्द्रिय उच्यते ।
वासनाविवेकेन भवाब्धौ न स मुह्यते ।। V:(ii) 163.15-1.

इति सर्वपदार्थानामभिन्नः परमेश्वरः ।

कल्लोलसीकरोर्मीणामब्धाविव पयोधरः ॥ VI (i) 60. 21.

विश्रान्तिमाप्तुमुचितां चिरमङ्ग दुःख-

रत्नाकरं जननसागरमुत्तितीर्षोः ।

को हं कथं जगदिदं च परं च किं स्या-

त्किं भोगकैरिति मतिः परमोऽभ्युपायः ।।

Vai(?) 116.12

एताश्च युक्तीर्मायावात्मा यत्नेन रचनां करोति न चोत्पन्नां तिरस्करोति सागर इव वीचि: ।। IV 59. 39.

देवासुरमनुष्याणां व्यवहारपरम्परा: ।
लोका: प्रवृत्ता आकल्पमासमुद्रमिवापगा: ।। VI (ii) 667.

अकालकल्पान्तदशासमुत्थानघनाकृतिम् ।
आक्रान्तरोदसीरन्ध्ररुधिरैकमहार्णवम् ॥ Vi(ii) III. 16.

आत्मतत्त्वैकघनया ततया ब्रह्मसत्तया ।
जगत्सर्वमिति व्याप्तं समुद्र इव वारिणा ।। VI (i) 100.27.

शिखिध्वजस्तु तत्सर्वं भाण्डोपस्करमाश्रमात् ।
एकत्रैवानयामास भुवो वार्यब्धिपूरिव ।। Vi. 92.23.

अधश्चोर्ध्वं च यावन्तश्चक्रावर्तविवर्तनैः ।
सर्वे तृणवदुह्यन्ते मूढा मोहभवाम्बुधौ ।। Vi(m) 77.26.

ततः समुदिते सूर्ये वितमस्यम्बरे स्थिते ।
समुद्रकादिव जगन्मणौ तस्मिन्विनिर्गते ॥ V. VI. 110.1

तस्मान्मदनिकादेहाच्चूडाला निर्गतैव सा ।
बभावस्य पुरो युक्ता निर्गतेव समुद्रकाद ॥ Vi(i) 108.37

अस्ति कश्चित्पुमान् श्रीमान् स्थानं नित्यविरुद्धयोः ।
गुणलक्ष्म्योरशेषेण यथाब्धिर्वाडवाम्बुनोः ॥ V.ii.188.1.

सूर्य, सूर्यप्रभा, आलोक.etc.

अस्मात्सिर्वनितो(द्भूति(तस्तु

अनर्थंमकरागारादस्मात्संसारसागराद ।

उड्डीयते निरुद्वेगं सर्वत्यागेन पुत्रक ।। Vi (ii) III. 9.

अन्योन्यपेते पूर्यैते समुदजलदाविव ।
योगगर्विचारश्च स्वात्मानोकश्च शाश्वत: ।। IV. 24. 63.

बृहत्कलकलारावं जेतुमब्धिमिवोद्यतम् ।
अतिदर्पितवास्तव्यमनपेक्षितपुत्रकम् ।। Vi (ii) 139. 30.

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] दि: ११।११. ६५.

प्रेम


कृपया ईश्वर त्रिभुवन-
प्रभु पूरण करें
आन्दोलनको प्रभु साद-
सिद्धि करो महान: ।
तेरा सुमे उन्नति से न
विनाश मेति
मेरा स्पंदन निवेदन
प्रार्थना है॥
Vizi 16.2 3.

सोने एक रत्नों याते
सोसें बहुमूल्य बहुमूल्य
स्वाभ मुदित भक्ता
बालक इव निर्मल ।।
८.१३.१९

al/as land fit to be plo
Yādavapr akāśa's Vaijayan
Arthaśāstra of Kauṭilya
ŪTA-- A fiscal t erm, requi
RD-STANDARD-- On early Gup
to it in the mention of
bearing representations

सर्वेषामेव धर्माणां कर्मणां शर्मणामपि

पण्डितः पुण्डरीकाणां मार्तण्ड इव मण्डनम् ।।




भगवंस्त्वत्प्रसादोत्था प्रतिभेयं पुरस्तव ।
नियोजयति मां वक्तुं कार्यं कर्तुमिवाक्षमाः ॥ V. 26.7.

ततो मुहूर्तमात्रेण स रुद्रस्तो नभोन्तरे ।

लण्हो विलोकयामास दृशार्कैणेव रोदसी ।। VI(ii) 86.3.

प्रमुदैत्यापितद्दुः स मुहूर्तेन तत्पयः ।
कृष्णाद्गौ कीं इव ध्वान्तं सत्संपर्कं इवागुणम् ।। VI (ii) 80.37.



उपशशाम् शनैर्दिवसैरसौ

कतिपयैः स्वपदे विमलात्मनि ।


नररसः शरदन्त इवापनै

रविकरौजसि जन्मदशातिगः ॥ V. 55. 23.

निरिच्छे संस्थिते रत्ने यथा लोकः प्रवर्तते ।
सत्तामात्रेण देवे तु तथैवायं जगद्गणः ।। IV 56.30

सर्वेषामेव धर्माणां कर्मणां शर्मणामपि ।
पण्डितः पुण्डरीकाणां मार्तण्ड इव मण्डनम् ॥

Vi (ii) 143.1.



विचित्रं विपरीतं च व्यवहारं महानिशि ।
अस्तीव भास्करालोकं दुर्भेद्यं चाह्नि वा तमः ॥ V(ii)145.65

दृशं विकासयामास तां तदार्क इवाब्जिनीम् ।
गृहीतसत्त्वसंपत्तिः शिखिध्वजमहीपतिः ॥ VI (i) 103.42

यत: साम्बुरिवाम्भोधौ न शाम्यति भवासनम् ।

नाभनस्था: संभवन्ति प्राणा: सूर्य इव त्विष: ।। VI(1) 69.33.

न. 6.

अधूमवह्निर्देहश्रीः श्रान्तोऽपि दैन्यमप्ययन् ।
तमो हरन्नृणां नैशं सुमणिर्वेश्मनामिव ॥ Viii 174.6.

चित्सूर्ये निर्मले दृष्टे नाम नश्येद्भवोदयम् ।
व्योमसूर्ये बहिर्दृष्टे यथा कृष्णानिशातमः ॥ Vi. 6.1, 81.104.

एतावताथ कालेन तयोर्जन्यत्रसोत्कयोः ।

प्रियं कर्तुमिवास्ताद्रिं द्रागित्यैवाविशद्रविः ॥

जगत्प्रसररूपस्य न देश उपयुज्यते ।

न कालो धारणे ऽप्यस्य आलोकस्याम्बरे यथा ॥ V.i.(ii) 13.1.

सति दीप इवालोकः सत्यर्क इव वासरः ।
सति पुष्प इवामोदः स्वतः संपद्यते जगत् ।। IX. 39. 43.

शाशाङ्कशीतलः पूर्णा भाति भासेव भास्करः ।
क्रियमाणा कृता कर्मतुल्यैर्देहशाल्मलेः ॥ V[illegible] 120.23

शाशाङ्कशीतल: पूर्णा भाति भासेव भास्कर: ।
क्रियमाणा कृता कर्मतुलश्रीर्देहशाल्मले: ।। V:(?) 120.23

अर्कबिम्ब इवादित्यश्चन्द्रबिम्ब इवोडुपः ।
महाम्भसीव वरुणः संध्याभ्र इव वा शशी ॥ V.(ii)130.17

Aṁśu or Aṁśujāla

Kiraṇa

Raśmi

शीतलानि पवित्राणि चरितानि विवेकिनः ।
इन्दोरिवांशुजालानि जनं शीतलयन्त्यलम् ॥ VI (ii) 47 8.

सङ्गादाह्लादयन्त्यन्तः शशाङ्ककिरणा इव ।
विवेक्तारः कार्याणां निर्णेतारः क्षणादपि ॥ Vi (ii) 98.4.

I.


शुद्धैः स्निग्धैः पवित्रैश्च मधुरैरात्मनोहितैः ।

मत्संगमनवद्गोरैरैन्दवैरमृतैरिव ।। Vi (i) 44.7

रसे नीरसतां याते वासना प्रविलीयते ।
शिखायां प्रविलीनायां प्रदीपस्यांशवो यथा ।। VI (ii) 51.41.

घनरसायनपूर्णपृशीतया विमलाया समया सततं श्रिया ।
शिशिररश्मिपरिवातिविराजसे विदितवेद मुखं रघुनन्दन ।। V. 76.2

अहिंसा समता तुष्टिश्चन्द्रबिम्बादिवांशवः ।
नोप यस्माच्चोपयाता महाभोक्ता स उच्यते ।। V.(i) 115.27



घनरसायनपूर्णपृशोतया विमनाया समया सततं श्रिया ।
शिशिररश्मिपरिवातिविराजसे विदितवेद्य सुखं रघुनन्दन ।। V.76.21

:

गतेन नृत्यतोत्थाय गृहीतगगनाङ्गनम् ।

अथोदपूज्ज्वनज्ज्वालाकिंशुकांशुकशोभितः ।। VI (ii) 75. 26.

अबुद्ध्या भानश्चेत्यादिचिद्रूपमपि बाधते ।
भ्रान्तिवदन एवास्य निर्मलाप्लवन्तरांशुवत् ।। V.[illegible] ९.१.

नूनमस्तंगतो यत्र तृष्णाकृष्णनिशाक्रमः ।
पुण्यानि तत्र वर्धन्ते शुक्लपक्ष इवेन्दवः ॥ V. 15. 12.

अहिंसा समता तुष्टिश्चन्द्रबिम्बादिवांशवः ।
नांप यस्माच्चोपयाता महाभांका स उच्यते ।। V.(i) (115.27)

नमस्कार मा० जोशी जी, पा-
रचनाएँ मिलता दिवारी रावत ।
सर्वो एव समुद्रमन्ता
तले पो० ई२५ ई२५ खबी
ता. १५.८.३

erfect chaos, all action being
; a stem and a stalk - all
erefore all objects having
causes, must have

Mountain as an Upamāna.

कृतोपकारविचारस्य मनोभोगादयो रयः ।
मनागपि न भिन्दन्ति शैलं मन्दानिला इव ॥ V. 79.17.

सममुखोग मानीताहे
सन्त एते दे यीमता
संस्कारानिदें निवृत्तानि
नवानां जिनत्रनिवो॥
८.१२.२०.

Manu).

(No.26).

means a superintendent. The word
Koṣas, hence its exact meaning can
from the fact that 'Uparika' was in
in a 'bhukti', we may infer that he
er

१९६ लो [illegible] मिदं। चित्र-

। मित्रस्य [illegible]

२ [illegible] प्रति [illegible] पाउा-

वि[illegible] [illegible] सूक्ष्मतेव

५।१।११.५५.

किन्नपतो महामेरुरिव देहः पतिष्यति ।
तत्र भूलोकशैलादि सर्वं चूर्णीकरिष्यति ।। V. (ii) 155. 48

धनुरास्फालयामास । चिरश्रावितदिङ्मु-
खम् ।
कल्पान्तपवनास्फोट इव मेरुगिरेस्तटम् ॥

चा. 48. 2.

(१७)

यानुपेत्य पापाचरणं करोति ।


ं नाप्नोति पूर्ण

कदा स्यामिन्द्रवनमहाशैलपुत्रकरूपिणी ।
द्यावापृथिव्योर्वैदूर्यस्तम्भतामनुतिष्ठति ॥

3.71:22

नम् । यः खलु सर्वनाथ दृष्टं वा
पादर्शन- मुपपन्नः प्रतिकूलः स तेना
प्यकतरं वैयर्थ्यान्वा यद्यपि । परिणामापु
ः परि स्वः । कालस्य तन्तु नितरां निपुण
। अत्र यद्यपि तदभवत् तदापि विदित वा
माख्यानम् । द्वै तावद्भवतिः सर्वमात्रै
नरः कापुरुषैः

महाप्रलय आसन्नो जगत्यस्मिंश्च संप्रति ।
ध्यानान्न च चलत्येषु शैलपीनादिवाचल: ।। VI (ii) 69. 8.




प्रसराम्भोदधूमाढ्याः फुल्लचम्पककाननाः ।
कम्पन्ते पश्य वातेन ज्वलिता इव पर्वताः ॥ V.(ii) 120.32

ज्वालापूर्णारिघट्टटोग्रखातापनयनत्रया ।
ज्वलद्रैन्दनोलादिसानूपमननाटभू: ।। VI (ii) 81. 25.

न कानिचित्प्रधावन्ति एकनिश्चयसंविदाम् ।
पुंसां सुखानि दुःखानि रजांसि नभसामिव ॥ Vi (ii) 100.11.

अवमानरजोध्वस्तपरस्तंगतवपुः श्रियम् ।
मुखं धूसरतामेति हिमैः पद्ममिवाहतम् ।। IV.66.23

न सज्जनाद्दूरतरः क्वचिद्भवे-
द्भजेत साधून्विनयक्रियान्वितः ।
स्पृशन्त्ययत्नेन हि तत्समीपगं
विसारिणस्तद्गतपुष्परेणवः ।। V: (ii) 98.29.



शक्रचापे यथा भान्ति नानाबर्णा नभोऽङ्गणे ।
तथा शून्यात्मका एवब्रह्माण्डपरमाणवः ॥ Vi(ni)125.66

नानावर्णा > ब्रह्माण्डपरमाणवः

प्राणो शान्तेतर स्पर्शे जीवो निष्पूर्ण-
मूकताम्। प्राप्ते शान्तो नमो-
वायौ न दृश्यते यथा रवः।
8. (i). 32, 28.

inescapable logical nece

objection is that the ex

relation between solar m

by the _reduction ad absu_

peculiar capacity of tim

एते मत्त: पलायन्ते समग्रा दुष्टचेतस: ।

नाणास्तिरस्संचारा: पवनादिव राशय: ॥ V. 31. 60.

reduction ad absurd

जगत्तया शान्ततया ब्रह्मतावतिष्ठते ।
पुंस्तया गत एवात्मा रैतोवटकणोजयोः ।। V.(ii) 38.15.

between solar mot

। विद् तोरन्ते सामि
स म ग्रा ु अवा ण वः।
मद्दु मा स्वर ता ि न्व सा
इव स्व ध्व पर स्पर हे॥
III. ४१. ३६

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

conquests up to th
central portion of
KANAUJ -- A town in the F
connection with SG,
KĀÑCHĪ -- A town in

ततः पिशाचकुम्भाण्डरूपिकादिमहागणाः ।
शवमावारयांचक्रुर्महाचलमिवाम्बुदाः ॥ V: (Ti) 134.26

शव > महाचल & पिशाच etc > अम्बुद

वातेनाभिहते लोके
न विना संभवन्ति ते ॥
एवं [illegible]
[illegible] ।
V. 72. 30-31

: : -

this title.

composition with 'bhaṭa'.(No.28).

expression meaning 'with th

the fuller

प्रममार्ज वनास्थां तां दृत: सुदृढनिश्चय: ।

प्रावृडौघस्तटगतां रजोरेखामिवात्मना ।। V.(i)92.9.

composit


न संवित्संस्पृशत्यन्तर्विविक्तो विमलो जनम् ।

जले गाधे निपतितं निमज्जन्तं रजो यथा ।। V; (6) 97. 38


प्रमपाजश्रिमास्थां तां संविदा शुद्धया हृदि ।

स्फुरन्तीं स्फुरणैनैव रजौलेखामिवानिनः ।। V.iii.72.15

परमात्मनि विघन्ते पयसो वेह पांसव: ।
भावनाशब्दशब्दार्थरंजनैयं जगद्तता ॥ IV. 41. 27.



सति पुर्यष्टके तस्मिन्, जीवः स्फुरति नोपले ।
सति वायाविव रजः सति दीप इवेक्षणाम् ।। V. 73.24.



कः पिता किं च वा मित्रं का माता
स्वबुद्ध्यैवावबुध्यन्ते वान्यथा जनपांसवः

V. 20.1.

पश्यतीदं तथैवात्मा स्वात्मभूतं
विशुद्धचित् ।
यथा सूर्योदये गेहे भ्रमन्ति
त्रसरेणवः ॥


III. 44. 36.

...वरीभूत ततः ॥ १५३ ॥

...ा यथा दातुमुपैति पात्रम् ।
...तुं सीव्यति सोपकारा ॥ १५४ ॥

...ा तद्यवनियवोन्मदन्ती ।
...तीं, पे ...ध्यान्न ...पि ॥ १५५ ॥

Flower as an উপমান.
আর্তব, কুসুম, পুষ্প etc.



कदाचिदनभिव्यक्तं कदाचिद्व्यक्तिमागतम् ।
इदमस्ति परे तत्वे सर्वं वृदा इवातंवम् ।। IV. 47. 57.

आर्तवं पुष्पमिति [illegible]

गच्छ तन्वङ्गि मा वैन पूजार्हमजिनौधनम् ।
पुत्रोष्वमे सतं कान्तं प्रसन्नमिव मन्नता ॥ IV. 51. 20.

विवेश मनसा मौनी ततः शास्त्रविवेकिताम् ।
दिनैरेव यथा पुष्पमामोदेन नराशयम् ।। Vi(ii)137.4.

तत्कालेनैष भगवान्संप्रबोधमुपैष्यति ।
मूलकोशरसाल्लोनं पुष्पजालमिव द्रुमे ।। VI (i) 103. 19.

।शिवा।भुत्वानला।शिखाखण्डात्य -
।भीतिरङ्गैः ।
समुद्दीननवाशोक पुष्प गुच्छाभिवा-
।भितः ॥

III 31.28.

उसमेँ घृत डाल कर
अथवा अन्य सामग्री
आर्यों की अन्य शा
प्रधान अंग होने के
का अर्घ आदि मेँ घृ
की जो भावना थी

दृष्टैर्वर्षमयं राम सर्गे क्षिप्रमन्त्यतिमागता ।
विविरि बहुपान्यनमः पुष्पन्दमोमेघोरिव ।। IV 44.48

सिद्धान्त काल एवैव प्रशस्ते एम राजते।
अकाल पुष्प माला हि शोभनापि न
शोभते ॥

III . 67 . 60

with you. The c
beyond the means
teacher. The Bh
lends it Mss. ag
value of the Mss
from there. Wi
same procedure
manuscript with
research socie

I shall k

प्रचण्ड पवनोद्धूतपुष्पाणीव महातरोः ।
अयः पिण्डादिवोत्तप्तात्ताडितात्कण-
पङ्क्तयः ॥

III. 48. 9.

तस्मिन्नस्तं गते वह्नौ तद्भस्मेदं सुशीतलम् ।
दुधाव कणशो वायुरशेषं पुष्पराशिवत् ।। VI (ii) 151.4.

विकाशितमम्लानमाहलादितशुभाशुभम् ।
त्वद्वचःकुसुमं नित्यं श्रीमत्फलदमस्तु नः ॥ V 4.32

गातैवस्त्रधारिण्यो नग्नसूर्यांशुकुङ्कुमाः ।
विचित्रकुसुमोपेताश्चन्द्रांशुसितचन्दनाः ॥ V. 50. 11.

तापिच्छपत्रवृन्दस्थपुष्पगुच्छसमोपमैः ।
तपद्भ्रमरैरालोढपीठमत्याम्रमण्डलम् ॥ VI (ii) 77.10.

तापिच्छपत्रवृन्दस्थपुष्पगुच्छसमोपमैः ।
तपद्भ्रमरकैरालीढपीठकल्पाग्रमण्डनम् ॥ VI (ii) 77.10.

महाकल्पान्त आयाते भवता भार्गवी तनुः ।
अपुनर्ग्रहणायैषा त्याज्या प्रम्लानपुष्पवत् ॥ IV. 16. 4.

प्राकृतो गुणावां जात इत्येषा भगवन्कथा ।

अकामपुष्पमानेव पुत्रायौदैवनाय च ॥ IV. 32. 27.

शनैरुन्मीलयामास नयने नयकोविदः।
पद्मः शिशिरसंशान्तावपरौ कुसुमे यथा ॥ VI (ii) 69.14.

तस्मिन्नस्तं गते वह्नौ तद्भस्मेदं सुशीतलम् ।
दुधाव क्षणाशो वायुरशेषं पुष्पराशिवत् ।। V: (ni) 151. 4

तस्मिन्नस्तं गते वह्नौ तद्भस्मेदं सुशीतलम् ।
दुधाव कणशो वायुरशेषं पुष्पराशिवत् ।। Vi (ii) 151. 4

फलाशङ्का मुधैवातिनिष्फला चित्तहारिणी ।
अकालपुष्पमालेव श्रेयसा नाभिनन्दिता ॥ V.(i)160.15.

वरमाप्नोति यो वापि विष्णोरमिततेजसः ।
तेन स्वस्येव तत्प्राप्तं फलमभ्यासशालिना: ॥ V. 43.35

वरमाप्नोति यो वापि विष्णोरमिततेजसः ।
तेन स्वस्यैव तत्प्राप्तं फलमभ्यासशालिनः ॥ V. 43.34

राजकार्याणि सर्वाणि तत्र संपाद्य सत्वरम् ।
शिखिध्वजस्य पुरतः पपात फलपुष्पवत् ।। VI (i) 104. 34.

इन्दुं मास इवापूर्णकालेन सुषुवे घटः ।
गर्भं कमलपत्राक्षं प्रसूनमिव माधवः ।। V(i) 86.13.

ऋणानिमिवा क्षयमाणानि पवित्राणि मृदूनि च।
सुखयन्ति गृहीतानि पुष्पाणीव वचांसि ते ॥ IV. 43. 2.

संसृत्यामोदपुष्पस्य दुःखदाहानलस्य च ।
जगदाक्रमणानलस्य मोहमारुतलस्य च ।। V. i. 1. 24. 2.

॥ [illegible]

रज के उपमान.

पुष्परेणु

परमाणु — अणु

राशयः

रेत

पांसवः

इयं दृश्यभरभ्रान्तिर्नन्वविद्येति चोच्यते ।

वस्तुतो विद्यते नैषा तापनद्यां यथा पयः ॥ VI (ii) 5.5.

शरदभ्रवदालूना मृगतृष्णाम्बुवत्तथा ।
पुन: संस्पृश्यमानैव बोधादुगच्छति दृश्यता ।। VI (ii) 51.24

न विवेतन्ति कल्पान्तान्सर्वाण्येव परस्परम् ।
एकमन्दिरसंसुप्ताः स्वप्ने रणारयानिव ॥ VI (ii) 60. 20.

यावद्रूपं तुरीयस्य किंचनापि न लभ्यते ।
सम्यग्बोधादृते शुद्धात्प्रकाशस्तमसो यथा ।। V.(ii).37.57 q.

एकत्वेनाशु संविचेयैर्यो मे जगदेकताम् ।
दुर्दृष्टेर्द्विवपुश्चन्द्रः सुदृष्टेरेकतामिव ।। Vi(ii) 138.11

पर तत्रेदंप्रत्ययः प्रौढो भवत्यनुभवो हि यः ।
शर भमायातमिदं भ्रान्तं तत्स्वप्नस्वोपमं विदुः ।। V:(रा.) 1.06.29.

परमाणुसमूहा ये जगदित्यप्यवास्तवम् ।
शशशृङ्गे पुनः प्रत्ययमज्ञानादभिधीयते ॥ V: (ii) 103.65.

समयौर्यंपयोप्रांत्रो व्यंवहाराय नामनो ।
यदत्क्रियेते द्वे तदज्जागृत्स्वप्ना शिनामये ।। V. (?) 106. 2

शाम्यन्ति संपरिज्ञाताः सकला दृश्यदृष्टयः ।
यथा महानदीवेगवारिग्रहणबुद्धयः ।। Vi(ii) 95.24.

अवश्यं खलु यन्नास्ति निर्बीजं तन्नपतिभ्रमः ।

खेन्दुत्वमर भूम्यम्बुवन्ध्यापुत्रदशासमम् ।। VI (i) 94. 64

यथा वदसि तत्त्वज्ञ तत्तथैव हि नान्यथा ।
चित्तं हि जीवन्मुक्तानां नास्त्यङ्कुर इवाश्मनाम् ॥ VI (i) 101.27.

गृह्णन्ति न महात्मानः प्राज्ञा जलदोनिव ।
स्वर्गमोदादिफलदं यत् किंचित्सर्वमेव तत् । VI (i) 101. 47

मिथ्यादृष्टिप्रेदितं तु न कदाचन विद्यते ।
मृगतृष्णाम्भसा केन घटका: परिपूरिता: ।। VI (i) 95.10

प्रमाकृति यदस्तीह दृश्यते लातचक्रवत् ।
मृगतृष्णाद्विचन्द्रादिबालवेतालकादिवत् ।। VI (i) 100.16.

द

गपुन: परे शान्ते न जाने क्वाशु गच्छति। 2.

चित्राग्निनेव बोधेन तेन जाड्यं न शाम्यति ॥

V.(ii) 45.55.

4.4.21.



अलं दूरगतास्तेषामङ्कुरा नभसो यथा । २.
जगदात्मा च नास्त्येव यस्यैकं सर्वमस्ति च ॥ V.(i)125.42

द
तस्यामवस्तुभूतायां कथं भावनिबन्धनम् ।
क भविष्यदाकाशतरौ विश्रान्तः को विहंगमः ॥ VI (ii) 49. 12.
नो

दण्ड...

क कथं केवलजागल्पमकारणमनर्थकम् ।
नो पराह्निक्षति अनन्यागताविव पादप: ॥ VI (ii) 51. 1.

कल्पिताथ मया तत्र कुटी प्रकटकोटरा ।

वीरन्ध्रकुड्यनिर्व्यूहा पद्मकुड्यालसुन्दरी ॥ VI (ii) 5633. ?

॥

V (ii) 4.4.26

दृश्यदृष्टिरिवं भ्रान्तिराकाशतरुमंजरी ।

चिद्व्योमाङ्ग कर्मैवेति तत्राहमनुभूतवान् ।। VI (ii) 60.26. ?

[illegible]

। दिन पुंसामधिकारले॥

V' (1') 44.21.

चित्रन्यस्त इवाकारमात्रदृश्यो विचेतनः ।
निःस्पन्द सर्वावयवः समुत्कीर्ण इवोपले ॥

III . 56 . 4 .

होती हैं, ि
है ठीक उसी
रस्ते की औ

सावकाश रहो ऽहम सावधान

ईश्वर तो सर्व विश्व वे।

न है लभ्य मानहे सर्वे

रूप गुरु सर्व प्रमाद का॥

विना १०.३.

जातो रात्नि गगनस्नेहैः
द्रावकाशमनुयान्वितो ॥
रागाविरागा ति युद्धे
मूर्धन्यतःल रविक्लवः ॥
Viii 5.5-

[illegible]
[illegible]
[illegible]
[illegible] ॥
८.११.७३.

LIST OF A

1. IA — Indian
2. API — Allahabad
3. Arch. Surv. W Ind —
4. CG — Chandr
5. C

[illegible]

[illegible]

[illegible]

[illegible]

[illegible].11.72

achau in their translations. None
ver Valabhi bore any such name as

official title, occuring nowhere

अनसानी को वास्ते
।चिदानन्द मनु पावनात्।
पुरनेरार्वन लियुत
सदा रामई मनोहिलाम्॥
५।१।११. १०४.

भाई नवे वेदवेलवादि-
पर्वलनकर निवारण करे।
५.१.३१. बा.

e Ganga -khadir Scheme

cts of U.P. More and more of land

ne of the best methods to settle th

is as effective today as it was

But it is not always easy to settl

ands unkess some inducmenets or ext

to them. In ancient India kings u

न मार्हेय मानानि
नेनसवित नवाहुः।
५।१।३१।७.

Gunaighar grant of V

and the Paharpur Cop

The ~~purhesx~~ purchase

land probably becaus

the freedom from ta

of religious donati

of land already til

यत्किंचिद् दृश्यते तस्मात्तल्लतया
महीपते: । फलपल्लवपुष्पादि
नाभिन्नं तन्मयं यत: ॥
6.(i) 33.19.

time, there is no motion ; how then do

---

a medhavi sammatah
im te patitalaksanam
nte ca kaka na
rvolokah patatyayam
Mahabhasya on III. 2. 123.

पुष्पपल्लवपत्रादि लताया
नेतरस्या । किं लौकिकत्वं जग-
त्वादि ~~स~~ त्वं नवाहन्त्वं तथा
स्थितेः ॥
6.(i).33.R.

-al and so do not ar

We cannot concl

words of the 'ideali

representation lyin

regard to phenomena

असम्भवतरङ्गैः स्म चिह्नितासम-
हाम्बुधेः । तराङ्गितत्वामिव पत-
तावच्चेतसाङ्गिता ॥
6.(i). 33.16.

of this process, the momen

that moment was accordingl

is yet to come and be effe

moment is future. And the

of this process, the momen

that moment was accordingl

तत्प्राप्तमधुना येन नाप्राप्तमवशिष्यते ।

दिष्ट्या दूरोज्झितानर्थमयैर्विषयोरगाम् ॥ V. 35. 47.

संशान्तमोहनीहारां शान्ताशामृगतृष्णिकाम् ॥

that moment was accordingl

तिलतैल & पुष्पामोद & पवनस्पन्द

मरीचे तीक्ष्णता, दिनरात्रे, छायाऽऽतप,

अनल-औष्ण्य, चन्दन-सौगन्ध्य, कज्जल-कार्ष्ण्य

हिम-शौक्ल्य, इक्षु-माधुर्य etc.

आसूतामन्योन्यमुत्स्त्रगृषौ सुहृदौ वल्लभौ मिथः ।
तिलतैलवदाश्लिष्टौ तौ पुष्पामोदवत्स्थितौ ॥ V. 65.24

अभिन्नयोरेव भृशं शून्यत्वाम्बरयोरिव ।
ऐकात्म्येनैव वसतोः पवनस्पन्दयोरिव ।। VI. (ii) 94. 55.

[illegible]

[illegible]

[illegible]

[illegible] ॥

Vi 2.5.2

6.

एको दृष्टे द्वितीयस्य
न सत्ता निरहङ्क्रियोः ।
हानौ वादाने वा योगी
इच्छां न प्राप्ति नापेक्षाम् ॥
Vi. vi. 6. 12

[illegible]

[illegible] ॥

[illegible] ।

U:11 3. 5-6.

एषैव मनसोन्मुक्ता चिच्छक्तिः
शान्तिशालिनी । सर्वज्योतिर्मयोमु-
क्ता वितताकाशसुन्दरी ॥
घनसौषुम्नलेखा व[illegible] चिद्यु[illegible]
लान्तः सन्निवेशवत् । सैन्धवा-
न्तस्थ रसवदन्तान्तः स्पन्दशालि
वते ॥
8. (1) 34. 13-14.

का ब्राह्मणों के प्रमाद

वाराणस

चौराहे में से गुज़रती

और सोचने लगते हैं कि

वृजत्सुयी

ययाँ शरी

रात में चन्द्रम

तो फिर ये यहां कै

वाराणसी के चौरा

यथा बीजेषु पुष्पादि मृदो राशौ घटो यथा।
तथान्तः संस्थिता साध्वी स्थावरेषु स्ववासना॥

VI (i) 10 - 19.

For similar reaso

pervading Reality whic

of entering into speci

that there must be a ge

general relation with e

is this something, this

As it moves and ch

to the notions with res

~~[illegible]~~

अन्तः सुप्ता स्थिता मन्दा मन्त्र बीज इवाङ्कुरः ।

वासना तत्सुषुप्तत्वं विद्धि जन्मप्रदं पुनः ॥

VI (i) 10-16.

Therefore, if Ākāśa
and thereby moves on ever
the first place, to enter
with all things, which it

वटश्च वटधानायामिव पुष्पफलादिमान् ।
सर्वशक्तिर्हि किंचित्वं सर्वशक्तिसमुद्गकम्

VI (i) 9-26

conceptual fusion of the V

of the language such as sl

Bhartṛhari in III. 9. 57.[2]

---

1. Vai su. VII. 1. 25.
2. Kalābhiḥ pṛthagarthābh
usaṁhāralakṣaṇaṁ taṁ p

प्रेमिणौ संमिलितौ रौ सममेव
परात्परात् ।
स्वयं कुर्वतां कान्तौ पुष्पा
मोदौ तरोरिव ॥
ता. १५.१.

Lucknow University "
welcomed by all scho
to my wife enclosed
evident to me that i
the research work of
fairness to him and t
his supervisorship at
able to devote the wh
research project in h

कृपया मे दाविवातिमन्नो
कृमान् धर्मं च राघव ॥
गा. ७५. 12

चाहते हैं । उचित का

का धर्मी के साथ संबं

विशेष के साथ संबंध

का हार गले में पड़

के और नूपुर पैरों के

के साथ माधुर्य गुण

है । दो वस्तुओं के

पहले

प्रतिष्ठापित करने

नात्मा शरीरमस्त्यात्मा
शरीरमनेव नात्मकी।
शिवो विज्ञानरूपावे
पुनारत्मतो सत्वा॥
Vi.ii.6.6



इसीलए इसे दिन जोगना
वालो के रख तेन छह।
विवेक का उद्भूमानों
मानसों निविचारण
सा है।
ता. १५. ३०

ebration of this anniversary which
d at the passing away of an evil
akasura.

cal significance of the festival as
t it signifies the removal of the
gnorance, in the recessès of the
, true knowledge. This day is
nest prayer of a devotee of God who

इला न वासना पर्य

पुनर्जन्म न कारेणी।

क्षीणा इ. दवैते हि

सांख्ये तिल तैलवत्

V. 71. 5ब.

REVIATIONS

tiquary

h Stone Pillar Inscriptions

eport of the Archaeological
urvey of West India

epta

India

orpus Inscriptionum

निरुत्त निरत त्वविच्छिन्ना चेत्यवे हि
निवृद्ध हा।भामेभ्या स्मृता ।
यथा नीच्या भाभेभ्याहि स्थितमबु
तरड्।केन ।। The relative mode of
6-(i). 33.15 with the past and the futı
of action (Kriyāsantāna) ‹
ing', he is cutting ; thi:

यथा शीकृत्यहिमे राम तिलतैलनवाँ यथा ।
यथा कुसुमसौगन्ध्ये तथौष्ण्यदहनौ यथा ।। V. 78. 5

अग्नयौष्ण्ययोरिव तथा वाक्स्पन्दनयोरिव ।
द्रवाम्भसोरिवा वीचिवा शैत्यानिलयोरिव ॥

Vi (ii) 143.19.



Taraṅga as an Upamāna.
Ūrmayaḥ , Kallola
Vīci

इमा याः परिदृश्यन्ते विनताः सृष्टिदृष्टयः ।
पयसीव तरङ्गास्ते पिच्छं व्योम्नीव वात्मनि ॥ V. 5. 36.

संपद: प्रमदाश्चैव तरङ्गोत्सङ्गभङ्गुरा: ।
कस्तास्वहिफणाच्छत्रच्छायासु रमते बुध: ।। Vi(ii) 93.78

(ही) करवी [illegible] ली ता ओगात
फओराशोरिबोसधि:।
सर्वा [illegible] कि.नि [illegible] ना
[illegible] हो ठीवराशाव:॥
ता. १५. २०

---

1. Aprthaktvepi saktibhy

2. Saktisca saktimadrup

Tadatmyamaynayornity

——— Bodh

उद्यमानं भवाम्भोधौ
वासन्तीमिव वल्लितम् ।
निर्गिरन्तीन्दियग्राहा
महानन्दपदारोहणाम् ॥

V. 13.6.54.

35.

NIHILAPATI-- An official ...

NĪVĪ-DHARMA-- The law of no...
for deposit which do...
i.e., permanent.

PĀDĀNUDHYĀTA-- Lit. 'medit...
ssion for the relati...
sovereign, of a subo...

parents, of a nephew

कुद्धो ज्योतिरिदं हि
न शरीरान्द निधने।
पश्यसो ज्योतिरेकेण
नरकान्ते महार्णवे॥
V.iii.37

इस पत्रके बारेमें श्री [illegible]

मोतीलालजीको लिखा।

आश्रमसे तो थोडे दिनोंका—

दान [illegible] [illegible] है ॥

V. W. 6. 17.

संसारसागरे दृश्यकल्लोलैरहमाकुलः ।

कालेनोद्वेगमायातश्चातको वग्रहे यथा ।। V (1) 93.35

तस्यां विभाति तदनन्तशिलात्मकोशे

लेखा व्यचक्ररचनादिवदेव दृश्यम् ।

व्योमात्मकं गगनमात्रशरीरवत्यां

चित्वाद्रवज्जलधिकोश इवोर्मिलेखा ।। VI (ii) 8



वृहतरंङ्गौ ध्वंभुजा श्यामलौ ल्लासशालिनौ ।

एकार्णवोर्मिमालेव नृत्तावृत्तिविवर्तिनौ ॥ VI (ii) 81. 20.

कल्लोलविकला: दुग्धसमुद्रपतिता इव ।
नाप्नुवन्ति स्थितिं स्वस्थां विकृताकृतयो धीन: ।। VL (ii) 47.

त्कन्दरोद्गीर्णां वल्लीवलयताण्डवम् ।
ना वायवो यान्ति विभिन्नाश्चाभ्रवीचयः ।।
Vi(ii) 114.28.


सर्वैः शलशलायद्भिरुष्णैरवयवैर्वृतम् ।
निदाघतापसंतप्तैर्मिंजालैरिवार्णवम् ।। V: (e) 137. 15.

अन्यत्प्राक्संनिवेशाद्द्वयं सादृश्येन विवल्गति ।
सदृशा विषमाश्चैव यथा सरसि वीचयः ॥ Vi(i) 77.8.

तां दृष्ट्वा प्राकनीं ग्राम्यापाहरद्वासनां बलात् ।
तटस्थं मुह्यमानाङ्गमिव वीचिर्महार्णवे ॥ Vi(ii) 147.18.

चिन्मात्रात्संप्रवर्तन्ते मनोबुद्ध्यादयस्तथा ।
आवर्तफेनकल्लोलवीचयो वारिधेर्यथा ।।

V(ii) 168.5.



अथ कालेन तत्तस्य गृहं नाशमुपाययौ ।
कल्पान्तरेणाब्द इव वातेनेव तरद्दगकः ॥ V.i.(i) 112.22

तद्देववृन्दमखिलं त्रिदशेशयुक्तं

तत्र क्षणादलमदृश्यमभूद्द्वितीयम् ।

कल्लोलराशिरिव वारिनिधौ प्रशान्ते

वाते स्फुरन्मकरफेनफणीन्द्रवृन्दम् ।। Vi:(3)107.32

परमात्मनि वाचेयमित्थं मायानुमीयते ।
तरङ्गानीव पयसि प्रेङ्खामात्रविनाशिनो ॥ VI (i) 67.9

प्रशान्तामृतकल्लोले केवलामृतवारिधौ ।

मज्ज मज्जसि किं द्वैतग्रहक्षाराब्धिवीचिषु ॥ U.G. 127.25

१४

प्रतिपिण्डदा यैते तु ये र्थाः सर्वत्र ते स्थिताः ।
अस्मदुदया परिच्छेद्याः सौम्याम्भोधिरिवोर्मयः ॥ VI (ii) 52.32

उन्मज्जन्ति निमज्जन्ति
उच्छुरन्ति पतन्ति च ।
तरङ्गा इव लोकानां निकायाः
प्रतिदिनं प्रजाः ॥
III. ४६. ५६.

How does the comm

question is answered b

It is the parts (

River as उपमान

भूमरेन्तावलोकार्थमयाप्युद्वेगवर्जितम् ।

प्रवृत्ता न विवर्तन्ते वहनात्सरितो यथा ॥ V.i.(ii) 131.5

5

मज्जनोन्मज्जनारावैर्विवर्तावर्तवेष्टनैः ।
अच्छिन्नानुपदं द्रोणा भाति सर्गसरिच्चिरम् ॥ V. (उ) 112.15

सङ्कल्पसातिम्मतां मणिमन्त्रेण
शोभय । तगोत्लमोनमात्मानं
समाश्वास्य भवामन्ताः ॥
6. (i) 33. 38.

that the whole world move

move.[1] That would be ind

Then there is a view

honour) that there is no

including the present. T

The wheel does not m

do not flow to the sea

करिष्यति दातगजवाजिसारथि-

द्रुतदारदुधिरमहानदीं भुवम् ।

शरोत्करप्रसरमहारज:स्थली-

तिरोहितद्युमणिविलोचनां दिवम् ।। VI (1) 59.17.


आधिव्याधिविलासानां राम साराधिसंक्षयः ।
सर्वेषां मूलहा प्रावृण्नदीव तटवीरुधाम् ॥ V. (i) Pr. 2.6.

अपूर्वाण्युपगच्छन्ति तथा पूर्वाणि यान्त्यलम् ।
संसारसरिदम्बूनि संगतानि धनानि च ॥ Vi(ii) 93.46.

प्रकृति: पुरुषं स्पृष्ट्वा प्रकृतित्वं समुज्झति ।
तदन्तरैकतां गत्वा नदोरूपपिवर्णवे । VL (ii) 85. 19.

वृष्टीव नदीपूरो यः समाधिकपरिस्थितः ।
तदैव तमायातं भूयश्चलति नो मनः ॥ VL (ii) 46 14.

मन्दाकिनीपयांसीव संगतानि विवेकिनाम् ।
प्रणाशयन्ति पापानि प्रयच्छन्ति विशुद्धताम् ॥ VI (ii) 47.



गरुडवेगेन दृश्यस्य नभसस्तथा ।
प्राप्तुं वहन्वेगाज्जगतः सरितामिव ।। V: (ii) 155. 30.

तुवं
ते ततो गरुडवेगेन दृश्यस्य नपसस्तथा ।
अनृतं प्राप्तुं वहन्वेगाज्जातः सरितामिव ।। V: (ii) 155.30.

कतुकैत्वन्तरेणेव सरितेवाल्पिका सखि ।
वातेनामोदलेखेव धूमलेखेव वागुँचा ॥

दृश्यदृशो बाधे बोधसारतयैकताम् ।
न्त्यशेषमहोपीठसरित्पूरा इवार्णवे ॥ V.(ii) 25.10

तावद्दूढो सुधाकाररसा संविन्महानदी ।
न यावदात्मरूपेण निपुणैरवगाह्यते ।। V.iii 12.7.18.


अनन्ताकुलकल्लोला विवर्तावर्तसंकुला ।
प्रवहत्याशयारण्ये तृष्णान्धानां नदी नृणाम् ॥ V. 15. 14.

ुष्पाः फेनहसनास्तरलातरलेक्षणाः ।

लासेना म्बुधिं यान्ति सरितो मत्यौवनाः ॥

Vi(ii) 145.12

र्ता:स्थित्यकारणं दोषाह्याधिदेहे प्रवर्तते ।
घा: प्रावृण्नदाधाभ्यामिवाकारविपर्यय: ।। Vi(i) 81.20.



Nihāra as an Upamāna.

...मसन्तु राजन्नमाशिलं

...रे मण्डलमिदं मुने।

...सुहामं ते प्रपश्यामि

...त्रिलोकीं हार...मिका भुवा ॥

V: 11 5: 5.

संविदं संविदाकाशे संरोध्य हृदि तिष्ठतः ।
स्वयमेव मनः शाम्येन्नीहार इव शारदः ॥ Vi(ii) 163.7

Compar...

, Rama,



Zorest as standard of comparison

Kānana, Vana,



विवेककल्पवृदो तु वर्धमाने दिने दिने ।
कायाविलानवनिते पुंसो हृदयकानने ॥ V. (ii) 44.30.

न मम्लौ दुःख शोकेन ।
रोमोद्गमेन न सिनाम् ।
जहर्ष च न भोगौघे –
स्थि दिवेगपदवीः॥
स्वरूपा [illegible]

5 (1) 12.16

सुरास्त्वाकर्ण्यं तद्वाक्यं जग्मुः स्वाभिमतां दिशम् ।
कमलापीदमादाय वनमालाभिवानिला: ॥ IV. 2. 8. 2

कोरकोच्छ्वसन्नधरा समग्ररसशालिनी ।

लतावरवनेनैव करपल्लवशालिनी ॥ VI (ii) 64. $\frac{50}{60}$.



उत्फुल्लकिंशुकवनैरुद्दीनैरिव वा वृतम् ॥
औवैंण चावृता आसन्फुल्लाशोकवना इव ॥ VI (ii) 75: 36.

कूजच्चकोरचयचारुलतानिकुंज

मुद्भासि नन्दनमिवागतमन्तरिक्षात् ।। VI(ii)152.18.

सत्वमेकं सुखं मन्ये न रजो न च वा तमः ।
चन्दुच्छवनानीव विकीर्णाङ्गारवर्षिणः ।। VI (ii) 75.56

शिरोमन्दाश्रितोग्रागिन्दग्धस्थाणुवनावनिः

कल्पान्तवातव्याघता वनमालेव नृत्यति ।। VI (ii) 81. 98.

१ प्रा. [illegible] [illegible] प झाली?
[illegible] खराब झाली |
मूळव्याधीचा त्रास ऽऽताली पलल —
वेळ बनावली ||
Vi(:)1. 18.

Brahmā, creates all beings; the

-va guṇa, and known as Viṣṇu,

and in the awful form Rudra with

it.

p.t.o.

Fire as standard of comparison

संरोहतीषणाविद्धं
यथा परशुना छिन्ना।
न तु स्वजनोक्तिदुरुक्तं
प्रवीणविरुद्धं मनः॥
Vi(i) 2.50

जज्वलुः शस्त्रसंघाः ज्वलना उल्मुकानिव
जगर्जुः शरधारौघान्वर्षन्तो वीरवारिदाः ॥

III . 46 . 23 .

एष जीर्णो महान् दीर्घतपः समन्तात् ।
नी यथैवं तत्कोटरं त्वं प्रविशेत्य वायम् ॥ १७१ ॥

[नहेतनां तत्र नमस्करिष्याम् ।
ाण: सम्प्रार्थयिष्ये च यथावदेवम् ॥ १७२ ॥

ायो मनोरथं नःसफलीकुरुष्व ।
गुरुर्भवत्यनस्त्वं ननु जीवयेति ॥ १७३ ॥


वी यं दुःखान्निजान्तः पुरसंस्थितोऽस्ति ।

स ँ : ॰


इदं वाह्निमिवाघातुं चित्रसौधलताश्रयम् ।

अ


अनन्त इव विन्यास वनयौवनपावकः ॥ VI (ii) 75.38



तत्त्वावबोधो भगवन्सर्वाशातृणपावकः ।
प्रोक्तः समाधिशब्देन न तु तूष्णीमवस्थितिः ॥ V. 62. 8.




तत्त्वावबोधो भगवन्सर्वाशातृणपावकः ।
प्रोक्तः समाधिशब्देन न तु तूष्णीमवस्थितिः ॥ V. 62. 9.



सर्वं दक्कं ददाहौघैः शुष्कं वनमिवानलः ।

यथोद्भूज्जगत्खण्डशोषणाग्रोऽभवासरः ।। VI (ii) 75. 9.

40.



सर्वीदक्षं ददाहोच्चैः शुष्कं वनमिवानलः ।

अथोद्भूज्जगत्खण्डशो षणागोऽप्यवासरः ।। VI (ii) 75. 9.

सक्षमं रीघ्रविक्लोइता
ॐ कालिमानके: अमो इव।
कवालिएको लिंगानितारस्माइ
इहम्यो नीवरारख्यम्॥
III. ९५.२२

Bhartrhari repeats t

is <u>Svatantrya Sakti</u>, as i

how Kala which is <u>vibhu</u>

urges all Kalas (Saktis)

are comparable to the re

The question arises

Brahman or different fro

(as Hari undoubtedly is)

प्रशेमुरथ हेतीषु प्रोद्यत्करकटारवाः।
रक्तार्णवपयः पूरैर्वाडवा इव वह्नयः॥

॥ 46.19.

पुण्यान् नदाशो विंषया

ना नो न्मदन्तो त्यभिधी
यां वीक्ष्य विप्रे विंहृतिं

धान्यादिदानी यक्षिपा
गृहस्थधर्मं परिपालयन्तो

काले व्यतीते श कदाचि
[illegible]

अभ्युल्लसत्कटकटारवमुक्तगन्ध-

व्याप्ताम्बुवाहपटलो दिशवयं हुताशः ।

दन्तो सरन्ध्रमिव वेणुवनं समन्ता-

दुदान्तपेदुररवं दल्यांचकार ॥ V. 44. 40.

संध्याप्रप्रथमार्काभो वृद्धिमभ्यागत: क्षणात् ।

गालयत्यखिलं साङ्गं देहं हेम यथानल: ।। V:(i) 82.4.

पिण्डाहृतायामदुर्गन्धिगुण्ठीकृतककुब्गणाम् ।
एकगर्भाभ्रनिर्व्यूहः खादिरज्वलनोज्ज्वलम् ।। V.(ii) 134.26

किरन्विग्निकणासारमभितः स्वप्रतापजम् ।
मध्याह्नसूर्यकान्ताग्निरिव ज्वलति यो रिपुः ॥ Vi.u,74.7

दुःखाग्निदीपितमना मनागपि विभूतिषु ।
ताल्वभोष्ठोपनीतासु नै रेमे गिरिशिखास्विव ।। Vici 84.2

चिन्तनेनैधते चिन्ता त्विन्धनेनेव पावकः
नश्यत्यचिन्तनेनैव विनेन्धनमिवानलः
V. 21. 6.

मरुद्वहव्यगौरीशवीर्यग्रासादिखेदिताम् ।

जीवन्मुक्तो वहत्यग्निर्यथा स्थित्या समस्थितिः ।। V:(ii)125.57.

[illegible] ।

[illegible] ।।

पावनीयं तव मतो राजते घनरूपिणो ।
विवेकेनानलेनेव कनकद्रवसंततिः ॥ ~~U:(ii) 6.9.7.7.~~
U: (ii) 7: 3.


तथाहुः श्रुतयो बह्व्य एवमेवैक्यमादरात् ।
यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् ॥ V. (i) 128.29

मेदः पटैरावलिताखिलाद्रौ
कष्टं स्थिता संप्रति मोदना भूः ।
मेदोमयैः शारदमेघजालैः
सकम्बलानीव वनानि भान्ति ।।

Vi (ii) 135.4.

शैवाल.


लोला शैवालवल्लीव व्यालोलाम्भोधिलंघिता ।
अथ दुर्वारनिर्घोषनिर्वाताडम्बरान्विता ।। VI (ii) 71.49.



Straw (Tṛṇa) as an Upamāna.

किरातक

उत्तप



तृणवन्नोपकुर्वन्ति यत्र त्रिभुवनश्रियः ।

सा परा निर्वृत्तिः साधो नैराश्यादुपलभ्यते ।। V. 74.45.

आवर्तेषु तृणानीव भ्रान्ता विगतसंभ्रमम् ।
चिरं चंचलमत्ताभ्रवृन्दमण्डलशोभिषु ॥ VI (ii) 122. 9.

चित्रमेष त्रिनेत्रो पि जीर्णं तृणमिवार्णवे ।
उह्यते हा हतविधेर्नां कार्यं नाम विद्यते ।। Vi (ii) 139.49

नीयन्ते नियमाधूता मानवा मानवायुभि: ।
काम्यकै: स्फुटतापूता: किराकनिकरा इव ।। Vi(ii) 92.39.

[illegible]

[illegible]

[illegible]

[illegible] ॥

वि ६।१२।२५

ચનનોલા મોલિકોને
એને બધે નના ૬૦૫ હૈતે ॥
જે ઘતે ક્ષ પક્ષૂરં
દ્યૌં ગીરિ નદીઓ લિ કૃ:।
૪.૧૨.૫૩-૫૪.

the great forest reg

tradition". The Ma

route to Deccan, ide

Sonapur, extending a

हेतिभास्वराः स्निग्धोष्णकरस्पर्शात्तेतो-
ऽञ्जसा।

तृणानीव गताः प्रोह्य स्पर्शात्प्याभवन्मुनः॥

III.48.69.

disturbed
the lake while constructing a seri
er the death of king Jayapida, one o
ry was again overtaken by floods.
letely averted during the rain of
. In order to stop floods his able
several irrigation canals and
ich help the country from the perenni
it on the rode to prosperity.(XV.

स्वेन दौर्भाग्यदैन्येन न परमाप्युपतिष्ठते ।
वेत्ति नित्यमुदारात्मा त्रैलोक्यमपि यस्तृणम् ।। (V. 32.37)

योमो भासौ दृढ इति नामभिः परिज्ञाः कृताः ।
जगत्तृणमिवाशेषं पश्यन्तः पावनाशयाः ॥ (V. 34.9.

चित्रमेष त्रिनेत्रो ऽपि जीर्ण तृणमिवार्णवे ।

उह्यते हा हतविधेर्न कार्य नाम विद्यते ।। VI (ii) 139. 49.

. . . . — . ' — ८१.

० . ९` . ·/ . . . ।। —

ਅੰਮ੍ਰਿਤਸਰ ਤਾਰੀਖ: ....

प्रज्ञाविरहितं मूढमापदल्पापि बाधते ।
पेलवाचानिलकला सारहीनमिवोत्पलम् ॥ V. 12. 21.

गतसकलविकल्पो निर्विकारो निरामः

सकलमलविलासोपाधिनिर्मुक्तमूर्तिः ।

विगलितसुखमाद्यं तत्सुखं प्राप यस्मिं-


स्तृणमिव जलराशावुह्यते शक्रदम्भः ॥ V.55.24.

अथ सर्वार्थीरिकं तत्खिन्नप्रकृतिपरिकम् ।
सोमान्तिने तृणमिव राज्यं स्वपरयै ददौ ॥ V (i) 75.5

गदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः ।
यथा तृणादिकं क्षिप्तं क्ष्मायां लवणं भवेत् ।। Vi(i)12 P.30

इहोह्यन्ते जनैरेवं तरङ्गान्तस्तृणैरिव ।
परणाव्यपदेशात्तु देशकालान्तरोहितैः ।। V. 71. 66.

न जातु ते विगण्यन्ते गणनासु गरीयसाम् ।
ये तरङ्गैस्तृणानीव ह्रियन्ते हर्षशोकयोः ।। V[illegible] / 127.50



आवर्तेषु तृणानीव भ्रान्ता विगतसंभ्रमम् ।
चिरं चंचलमत्ताभ्रबन्द्धमण्डलशोभिषु ।। Vi(ii) 122.9.

मूर्खस्य तु मनस्त्यागो नूनं दुःसाध्यतां गतः ।
पामरस्येव साम्राज्यं तृणस्येव सुमेरुता ।। V. (ii) 94.7.

V. (ii) 4.2.30

रुद्रोपेन्द्रादिपूजात्र वरतृणालवायते।

विचारशमसत्संगबलिपुष्पैकपूजितः ।।

V: (ii) 42.30

पाषाण, शिलाetc.

उपल. स्तम्भ




अहंतापुटकोड्डीनपरबोधभ्रमिरतः ।

अहमित्यर्थपाषाणो न जाने क्वाशु गच्छति ॥ V. (ग) 17. 3.

अर्थौ दृष्टदिवाम्भोधौ यो य आपतति त्वयि ।

५ तस्मादेव पलायस्व नाहमित्येव भावयन् ।। U.(ii) 5.17.



शिलापुत्रकसेनायां पाषाणात्व इवास्थिते ।

प कार्यकारणवैचित्र्यं कथं संभवति क्वा वा ॥ V.(ii) 42.22

" VI (ii) 57.32.


साघो हृदयसौषिर्यंमसौषिर्यंमिवास्तु ते ।

अचित्ववपुषो चित्वादुपलस्येव राघव ॥ Vi (ii) 22.52

उड्डीयमानमात्मानं शिला: शैलस्थलानिव ।
घनघुंघुमसारावानक्रभ्रमणादि च ।। V:(ii) 145. 36.

—नम ।

प्रपभूतेन कुमीश्चैत्रवहारमवस्तुना ।
तत्प्रकाशात्परं निशादि: कान्तत्वं न नोद्यते ।। V.(ii) 37.57



चतुर्धा भित्तिभेदेन वृद्धबालाङ्गनान्वितम् ।
जगाम शतधा वीच्यां शिलायामिव निर्झरः ॥ V.(ii) 139.34

नाहमस्मि न चान्यो स्ति सर्वं नास्तीति निश्चये ।

प्रकृतव्यवहारस्त्वं शिलामौनमयो भव ।। VI (ii) 57.32.

-- ...र्तिचमा' ।

शङ्खपद्मादिकं लोकं पाषाणो लिख्यते यथा ।
भूतं भवद्भविष्यच्च शिलायां शालभंजिका ॥ VT (i) 46. 20.


... र्गीविभ्रमा: ।

→ 79


यथा शिलान्तर्रेखादि भिद्यते न शिलान्तरात्
तस्मात्त्वाज्जगत्भृतं कर्तृत्वादिजगच्चितिः ॥ VI (1) 46.36

परमार्थनिजामोदा: सहजा: सर्गविभ्रमा: ।
नोधन्ति नोपशाम्यन्ति लेखा इव शिलोदरे ।। V(ii) 37.79

... जा। इव ।। V(ii) 2 5.26



स वासनावेशवच्छिन्ना: सुविकारशतात्मभि: ।
ठ व्रजन्त्यघौघो धावन्तं शिला: शैलच्युता इव ।। V.(?) 25.26



सर्वे एव त्विमे भावाः परस्परमसङ्गिनः ।
अटव्यामुपलानीव भावनैतेषु शृङ्खला ।। V.(टी) 26.2.

नो कर्तृता न च जगन्ति न भोक्तृतास्ति ।
नास्तीति नास्ति न च किंचिदतो बुधः सन् ।
पाषाणमौनमवलम्ब्य यथाप्रवाह-
माचारमाचर शरीरमिहास्तु मा वा ।। VI (ii) 62.46.


तत्रासिमुसलप्रासवज्रचक्रगदादयः ।
दैतेयः कुण्ठतां यान्ति दृषदीवोत्पलाहतिः ॥ प. 2.3.15.

बुद्धोबभूवासौ विचरं नयचेतनः ।
...प्राणादेह इव वा तूलात्मैवेव वा लघुः ॥ Vi (ii) 93.22


6.

तं ब्रह्मदत्तस्य तरङ्गमिव वाम्बुधेः ।
त्कीर्णप्रकटना शिवत्स्तम्भे चारुपुत्रिका: ॥

Vi (ii) 147. 8. 5. 6.



पर्वताग्रपरिभ्रष्टो ह्ययघोघ उपलो यथा ।
परमात्मपरिभ्रष्टो जीवः स्वप्नमिमंब दृढम् ॥ ग. (i) 65.6.



अप्राप्त

काकतालीयवत्साधो केषुचिद्दुष्टकर्मसु ।
समं पतति दुःखादि पादपेष्वशनिर्यथा ।। Vi (ii) 149.22

व प्र

सलिलौघौतवप्राणामम्भोधितटभूभृताम् ।

नूपुरैरिव रत्नौघैः पादा भान्ति ध्वनन्ति च ॥ VI (i) 120·30.


गुलूटेन क

गुला

अस्माद्वनतरोरेताः स्वच्छा गगनाङ्गणे ।
दृश्यशाखाः प्रवर्तन्ते जगज्जालगुलुच्छकाः ॥ V.(ii) 34.34

तेनैयमुर्वी नीरन्ध्रा भूतैर्मर्त्यैरमृत्युभिः ।
दीना प्रपन्ना गुर्व्येव भारभूतैर्भविष्यति ॥ VI (i) 52.25.


लेख (किल्बदिनाज)



द्विगुणा नभसस्तस्माद्‍दृष्टा चक्रस्य पुष्टता ।
दशदिक्षु विसरतो बिल्वत्वक्सदृशस्थितेः ॥
Vi (ii) 127.17.


षोडश:

प्रियाबिम्बाधरस्वादुरसवत्कौसुमं मधु ।
प्रमत्कुसुमसंधासु मुक्तावल्ली विनाविषु ॥ VI (i) 62.23.




[illegible]

संप्रबुद्धो भवन्ते च जीव: संबुद्धवेदन: ।
शिशिरदग्धेऽनागात्रस्य यथा विव रसन्तरो: ।। VI (ii) 56.40.



स कालदेशतो देहाज्जगीत्वमुपागतात् ।
वासनावशतो याति स्पन्दापणादृशो यथा ॥ VI (i) 55.20



कदली. आम्र
रम्भा
शाल्मलि: दाडिम.

सत्प्रज्ञोन्नतिमायाति शास्त्रार्थरसशालिनी ।
विवेकिनो विलासेन कदलीव महावने ।। VI (ii) 47. 14.

जगतां तत्र लक्षाणि नाशोत्पातशतानि च ।
मया दृष्टानि रूढानि कदलीदलपीठवत् ॥ VI (ii) 90.29.

जीवान्तर्जायते जीवस्तस्यान्तरपि जीवकः ।

सर्वत्र रम्भादलवज्जीवो जीवान्तरैव हि ॥ IV. 18. 62

तेष्वप्यन्तस्थसर्गौघाः कदलीदलपीठवत् ।

सर्वसर्गान्तरादूरं पत्रपीवरवृचिमत् ॥ IV. 18. 17.

मुने चेतनमेवाद्यं कर्मणां बीजमुच्यते ।

तस्मिन्सति महाशाखो जायते देहशाल्मलिः ॥ V. (ii) 2.27.

संसारकदलीस्तम्भाद्विना संकल्पपल्लवम् ।
मृदुनो पि तृणाङ्कुरान्न किं कल्पते ज्वरम् ॥ Vi(i) 112.18.

उपर्युपर्यन्तरत: कदलीदलपीठवत् ।
श्लिष्टाश्लिष्टस्वरूपा: स्वै मिथ: संवृतय: स्थिता: ॥ V.(ii) 18.3.

१६७७८

रम्भास्तम्भो यथा पत्रमात्रमेवं पुनःपुनः ।

अन्तरन्तास्तथान्तश्च तथा को णुः स एव हि ।। VI.(ii) 70.15

नित्याभ्यासविवेकाभ्यां चित्तमाशु प्रसीदति ।
याम एव दशामेति साङ्कारीं शनैः शनैः ।। V. 43. 32

जगन्ति वातैर्वलन्ते व्योम्नि शाल्मलितूलवत् ।
नोह्यन्ते नोपलभ्यन्ते न च सन्त्येव कल्पनात् ॥ [illegible] / 2.43.

सुरासुरनराधारां रगर्भंमधंमनोहरम् ।
पृथक्कोष्ठस्थबीजौघसंपूर्णमिव दाडिमम् ।। Vi (ii) 147.14. 8.

रम्यागमं इवासारो व्यवहारो विचारग: ।
सत्वरं युवता याति कान्तैवाप्रियकामिन: ।। Vi (i) 78.8.

वाडव
दवानल व उपमान.

भ्रमन्तो त्रिदशेनासु सदा नमसि मानद् ।
त्वदृते नेह पश्यामि घनाज्ञानदवानलम् ॥ VI (ii) 65.25

स तच्छापहुताशो थ तस्मिन्नेव तदा क्षणे ।
असुरं भस्मसाच्चक्रे जलमौर्वं इवानलः ।। Vi(ii) 136.13.

विनाशवाडवाक्रान्तं भीमं काममहार्णवम् ।
जगज्जालतरङ्गिण्यो यान्ति भूततरङ्गिकाः ॥ V.xii/118.12

अथ तस्य मुखं स्फारं ज्वालामालाकुलान्तरम् ।
प्राणाकृष्टो महाम्भोधिर्वडवाग्निमिवाविशत् ।। VI (ii) 80.34.

पीत्वा घृत्वा चिरं कालं गर्भे पुरुषतापिता: ।
वैयाम्पिव हितास्तत्र सागरा वडवाग्निषा ॥ Vi(ii) 109.37.

जाल का उपमान.

तत्रापश्यदसौ सर्वं विषण्णावदनं जनम् ।
जालं कुङ्कुमपुष्पाणां मुकमूलमिवांशुना ।। V. 46. 21.

विमुच्येय घनास्तीर्णाज्जालादिव विहंगमः ।
अहो नु चिरकालेन विवेके सुविकासिनि ।। V. [illegible] 117. 8



Sky as उपमान.

वाचामतीतविषयो विषयाशादशोज्झितः ।
काममप्युपगतः शोभां शरदीव नभस्तलम् ।। Vi.(ii) 122. 3.

गते तस्मिन्कचो देहाद्वल्कलाद्यप्ययात्यजत् ।

गतेन्द्रभ्रार्कतारेण शरद्व्योम्ना समो भवत् ॥ V.iii.iii.16.

दं तनुभुवनगगनगिरिगणा-

करणापरं परमप्रज्ञानम् ।

वगलति गलितं तस्मिन् ।

सकलमिदं विद्यमानमपि ॥ VI (ii) 51.48

परमन्त्री नामकलितोत्सुक-
नी चेलचर्चनाम् । मनोमोहा
भ्रान्निर्मुक्तर शरदाकाशा कोश-
वते ॥ 6.(i).34.9.

ण में व्याख्याता

युक्त-

मा। वि। डि। मा मलाभोरबे

रवचंद्र इलेक्शन कैसरबी॥

ध्यानी ५५.१५.

amla Nagar, Delhi.

the September 18th,1957.

ary,

मोरन्यों सूचितो सूतं किरो
भित्तें राम सकानन्यानम ।
विनीनान्नु धरे ऽयोनि
ज्ञाइयं रानम्य याविइनान
V:(1 L. 5

महान रहे, गान्धी जी –

भारत मा के दर्शक हैं।

राष्ट्रपिता [illegible] हैं

[illegible]

स्वविवेकानलैः कृत्वा सङ्कल्प-
जलदक्षयम् । परां निर्मलता-
मेहि शरदीव नभोऽन्तरम् ॥
6.(i) 33.37.

...) ; of the former kind is the
...ing', which consists of several actions
in 'the action of cooking' comprising
pot upon the oven, pouring water into
it, fetching fuel etc.. The act of
...oken of as present, thus consists of an
...verse operations of which only one is
... others, future. Collectively they

यथैव व्योम मरुति लीनम-
पुच्छिकं भवेत्। तथैव तत्रैव
तदा लयमेति मनो मुने।
6.(i) 32.37.

hat is past, existed and action for
past ; the moment that does not exist,
ed ; the action qualified by that
is no such moment as may be both
or that would be self-contra

तं शून्यता शून्यते या
शिलाये शरा इच दुग्धः।
प० १।२१।११

शून्यताशून्यतानाम महतीरव
इवारवता ॥

The people could hold
came from outside. T
literature of the big
was generally paid in
store houses

ये हि पारंगता ब हेः
संसारा च रूपस्थ च
ते वै तदास्य ट्रष्यार्ं
पवना ना भिवाक्कर्म ॥

५. १०. ३०.

- : :

bears the legend

Mxxxxxx-person.

MIHIRA-- A tribe or cla

Mihirakula belon

name i

अपश्यत्पतिनिर्हीना शयनं शून्यतां गतम् ।
अभास्करमपूर्णेन्दु शान्तशोभमिवाम्बरम् ॥ V.i.(i) 85.3.

- : : 19 :

द्वैताद्वैतविवादेहा हृदयाकाशमंजरी ।
विनैतयेह नोदेति प्रबोधाकाशमार्जनम् ।। Vi(ii) 163. 3P

- : : 19

प्रशान्तकलनारम्यं चेत्यरिक्तविदास्पदम् ।
पदं जगाम नीरागं पुष्पगन्ध इवाम्बरम् ।। V 19. 19.

- : : 19

न्ये विपुलाभोगे स्वच्छचिज्जलपूरिते ।
ापद्ङ्ककलिने भविष्यति चिदम्बरे ॥ V(ii) 94. 67.

- : : 19

अथ दाणोन सलिलं तदशेषेण निर्ययौ ।

वीच्यग्रस्फुटिताकारैर्दैवैस्तारकिताम्बरम् ।। Vi(ii) 140.13.

1

- : : 19

अथ चिह्नयोमतां प्राप्त: परां दृष्टिमहं गत: ।
शरत्समयसंप्राप्तौ व्योम निर्मलतामिव ।।

– : : 19

दग्धाभ्रमस्पसंपूर्णधूमाभ्रासितकम्बलैः ।
आनीलाकाशदलपैरिव संकादिताम्बरः ।। Vi(ii) 150.43.


- : : 19

सर्वसंदेहदुर्ध्वान्तमिहिकामातरिश्वना ।

भाति भास्वद्धिया देशस्तेन पूर्णेन्दुनेव खम् ।। V.(ii) 39.4.

- : : 19

यस्य वीर्यं सुवीर्यस्य न शस्त्रैर्न च पावकैः ।
केनचिद्भुवने कान्तमाकाशमिव मुष्टिना ।। IV. 52. 9




यथा रजोभिर्गगनं यथा कमलमम्बुभिः ।
न लिप्यते हि संश्लिष्टैर्देहैरात्मा तथैव च ।। V. 5. 31.

कोटर

कल्याणाधन नीहारो मे रहे-
दुर्जोगु संचरितई।
शालमनोरमलं दूलमछीला-
कोटरोविनी॥
III ४.५.२१.

lt perfect chaos, all action being
a sprout, a stem and a stalk -
her. Therefore all obj... all

अनन्तः सत्स्वरूपस्त्वं स्वमिवाविततान्तरम् ।
प्रकाशो नित्यशुद्धस्त्वं ज्वालानामिव कोटरम् ।। ८



जगी

उछाला.

मोतीलाल ने पैसा वापिस कर दिये
इजाजत न दी।
vi(i) 31.10.

India is blessed xxxkx
copious rainfall. E
are not specially fa
the human ingenuity
artificial irrigati
and wells.for irri
We find th

प्ररोह, कोरक.

Sprouts or अंकुर ०० उपनाम.




तयोरथैकास्पदयोस्तत्राभूतां सुतावुभौ ।
फुल्लाह्दुरौ शुद्धतनू सरस्यम्बुजयोरिव ॥ V. 65. 22

शैशवाङ्कुरितोज्जृम्भान्नवयौवनापल्लवः ।
जराकुसुमितो प्येति पुनः संसारदुर्द्रुमः ॥ V.66.1

यावदन्तर्गतः सर्गः संस्थितो ऽङ्कुरितोपमः ।
कुसूलस्यैव बीजस्य सिक्तस्यैवाङ्कुरो हृदि ॥ VI (ii) 87. 2

इति संरक्षितादस्माद्ध्यानबीजात्प्रवर्तते ।
वाभिजात्योन्नत: श्रीमान्विवेकाख्यो नवाङ्कुर: ।।



गीबों का र खोदे विव्यान्ति
मधा:विन नवकुं• रार।
सा — १ क.
तनैं व ल मसे व्यान्ति
जुीत्मे मधुर सा इव॥

[illegible]

का किसी चौकीदार संविधान में जा

स के साथ एक नौकर रखने वाला उसका

नजरों है निगाहें लगता है। उसकी यह

होती है और काफिर यह अलंकारों की

— क्योंकि आविष्ट कलाकार है अपनी ही

लोचर में झिलमिला उठी और अलंकार बन

उसकी रचना है

[illegible]

[illegible]

[illegible]

[illegible]

८।१०।१८

पितेवत्विग्रहं चेतः
सन्तापमीशोमिऽभ्यपैतो।
भूयः प्रयाति सो मेऽद्यं
देवालीनामिवाङ्कुरम् ॥
V. i. 12 (1).

एवं विश्वशान्ति

नारी बनना चाहूँगा।

सुनते हम [illegible]

उन्नत [illegible]

[illegible] ॥


५/१/१७.१५



क०८ करश्चैति धमर्मो र्द्वद्धुःरद्व

स्थलात् ॥

VI (i) 6 – 38.



कपटकरचैति धमको दुर्वोहुरइव


स्खलात् ॥

VI (i) 6 - 38.

... we see development, now
creepers, trees; other causes remo
...nge (parinama) is due to, is time.
account for the use of such terms
...he Bhasyakara's answer is that it
...[4]
Elsewhere,[5] the Bhasyakara decl

...eyapneeyah prthak

अहंकाराङ्कुरः दृष्टो हृदयेनावरोपितः ।
सहस्रशाखं दुश्छेदं तस्य संसृतिनाशनम् ।। IV. 33. 36.




य स्वयमेव हि कालेन प्रबोधमयमेष्यति ।

प बीजकोशात्स्वसंवित्या सुप्तमूर्तिरिवाङ्कुरः ॥ V. 28.18

[illegible]

अत उत्तरपैतेन गर्भता दनुजन्मना ।
न कर्तव्या प्रदग्धेन बोजेनेवाङ्कुरक्रिया ॥ V. 33. 3.




य

इच्छासंदूषिताकारं कर्मवृन्दावनाङ्कुरम् ।

प्र सुविस्मृतोत्पत्तिपदं कल्पितानर्थकल्पितम् ॥ IV.43.41.

यस्य तृष्णाः प्रम जन्ति हृदयं हतभावनाः ।
प्रोहमिव गर्धेभ्यो मरणं तस्य राजते ।। V. 39. 40.




नोदेतु त्वयि संकल्पो मरुभूमाविवाङ्कुरः ।

इच्छा नोदेतु भवति नतिकेवोपलोदरे ॥ U. III. 32

अस्मत्पित्रोरनीतानि पुत्रन्दाराण्यनेकश:
पत्रकोरकवृन्तानि लताविटपयोरिव ॥ 105.36

V. 19.33.



कोरकाविव पद्मिन्या वसन्ते गगनोन्मुखौ ।
आगुल्फमेव लम्बानि संपद्यन्ते म्बराणि मे ॥ V:21 105:36